CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library

SDPB

Coll. No. 884

Title Mudrārākṣasa

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 884 Subject: Nataka.

Title: Mudrārākṣasa.

Author: Viśākhadatta. Scribe: -

Date of the work: - Date of the Ms.: -

Place of the work: - Place of the Ms.: -

Size: 11" by 4.8" Extent: 41 foll. (no 1. missing)

Language: Samskrit Script: Devanāgarī

Remarks: Begins abruptly

गित्केड्डं। सूत्र॰ आर्ये॰ तिष्ठतु तावद्राजनियोगः कथय किमद्य भवत्याऽत्र भवतां ब्राह्मणानामुपनिमंत्रणेन कुटुंबकमनुगृ
हीतं॰ अथवा॰ अभिमतो भवन्मतिविषयः आत्मास्य देषपाकविशेषारंभः।नटी॰ अज्ज आमंतिदा मए भअवंतो बह्मणा। सूत्र॰ आ
कथय कस्मिन्निमित्ते॰ नटी॰ उवरज्जदि किल भअवं चंदोत्ति॰ सूत्र॰ क एवमाह॰ नटी॰ एवं खु णअरवासी जणो मंतेदि॰ सूत्र॰ आ
र्ये॰ कृतश्रमोस्मि चतुःषष्ट्यंगे ज्योतिःशास्त्रे॰ तत्प्रवर्त्यतां भगवतो ब्राह्मणानुद्दिश्य पाकः॰ चंद्रोपरागं प्रति तु केनापि विप्र
लब्धासि॰ पश्य॰ क्रूरग्रहः सकेतुश्चंद्रमसंपूर्णमंडलमिदानीं। अभिभवितुमिच्छति बलात्॰ नेपथ्ये॰ क एष मयि स्थिते॰ सूत्र॰ रक्ष
बु त्येनं तु बुधयोगः।।६।। नटी॰ अज्ज को उण एसो धरणिगोअरो ले वि य चंदं गहाहिओ आदो रक्खिदुं इच्छदि। सूत्र॰ आर्ये यस्त्वं
मया पिनोपलक्षितः ~~अभिभवितुमिच्छति बलात्॰ नेपथ्ये॰ क एष मयि स्थिते॰ सूत्र॰ रक्षत्येनं~~ नतोभियुक्तः॰ सूत्र॰ व्यक्तिमुपलक्ष्ये
क्रूरग्रहः सकेतुरिति पुनः पठति॰ नेपथ्ये॰ आः क एष मयि स्थिते चंद्रगुप्तमभिभवितुमिच्छति॰ सूत्र॰ आकर्ण्य॰ आर्ये॰ ज्ञातं कौ
टिल्यः।नटी भयं नाटयति॰ सूत्र॰ कौटिल्यः कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नंदवंशः।चंद्रस्य ग्रहणमिति श्रुतेः
स नाम्नो मौर्येंदोर्द्विषदभियोग इत्यवैति।।७।। तदनयोः कुपितस्यास्य पुरतः स्थातुं॰ तदित आवां गच्छाव इति निष्क्रां
तो प्रस्तावना।। ततः प्रविशति मुक्तां शिखां परामृशन् सक्रोधश्चाणक्यः।चाण॰। कथय क एष मयि स्थिते चंद्रगुप्तमभिद्वि

धा२

२ तुमिच्छति। यस्य नंदकुलकालभुजंगीः कोपानलबहलनीलधूमलतां। अद्यापि बध्यमानां वध्यः को नेच्छति शिखां मे॥ अपि
च। उल्लंघयन्मम समुज्वलतः प्रतापं कोपस्य नंदकुलकाननधूमकेतोः। सद्यः परात्मपरिमाणविवेकमूढः कः शलभे
न विधिना लभतां विनाशं॥१॥ शार्ङ्गरव शार्ङ्गरव (शिष्यः प्रविश्य) उपाध्याय आज्ञापय। चाणक्य· उपवेष्टुमिच्छामि। शिष्यः। उ
४ च्चि पाध्याय ननु इयं संनिहितं वेत्रासनेव द्वारप्रकोष्ठशालायां तदस्मिन्नुपवेष्टुमर्हत्युपाध्यायः। चाणक्य। वत्स कार्याभियोग एवा यन्नि ४
स्मानाकुलयति न पुनरुपाध्यायसहभूः शिष्यजने दुःशीलता। नाट्येनोपविश्यात्मगतं· कथं प्रकाशतां गतोयमर्थः पौरे
५ नि षु यथा किल नंदकुलनाशजनितरोषो राक्षसः पितृवधामर्षितेन सकलनंदराज्यपरिपणेन प्रोत्साहितेन पर्वतके
धा द्वैं सामलयकेतुना सह संधिं मतिदुपगृहीतेन महता म्लेच्छराजबलेन परिवृतो वृषलमभियोक्तुमुद्यत इति विचिंत्य नि
अथवा येन मया सर्वलोकप्रकाशं नंदवंशवधं प्रतिज्ञाय निस्तीर्णा दुस्तरा प्रतिज्ञासरित्· सोहमिदानीं प्रकाशी
गो भवंतमप्ययं न समर्थः प्रशमयितुमिति कुतएतत्। यस्य मम· श्यामीकृत्याननेंदून् अरिसुवतिदिशां संततैः
शोकधूमैः कामं मंत्रिद्रुमेभ्यो नयपवनहृतं मोहभस्म प्रकीर्य दग्ध्वा संभ्रांतपौरद्विजगणरहितान्नंदवंशप्ररोहान्दा राम·
ग्धाभावान्न खेदाज्ज्वलन इव वने शाम्यति क्रोधवह्निः॥१०॥ अपि च शोचंतो वनतेर्नराधिपभयाद्धिक्कष्टगर्भैर्मुखैर्मामवा २

सनतो ऽपकृष्टमवशेपदंदृष्टवंतःपुरा ते पश्यंतु तथैव संप्रति जनानंदं मया सांबयं सिंहेनेव गजेंद्रमद्रिशिखरात्सिंहासनात्पा
तितं॥१२॥ सोहमिदानीमवसितप्रतिज्ञाभारोपि वृषलापेक्षया शस्त्रं धारयामि। येन मया। समुत्खाता नंदा नवहृदयरोगा
इव भुवः कृता मौर्ये लक्ष्मीः सरसि नलिनीव स्थिरपदा। द्वयोः सारं तुल्यं द्वितयमभियुक्तेन मनसा फलं कोपप्रीत्यो
र्द्विषति च विभक्तं सुहृदि च॥१३॥ अथवा अगृहीते राक्षसे किमुत्खातं नंदवंशस्य किं वा स्थैर्यमुत्पादितं चंद्रगुप्तलक्ष्म्याः
(विचिंत्य) अहो राक्षसस्य नंदवंशे निरतिशयो भक्तिगुणः। स खलु कस्मिंश्चिदपि जीवति नंदान्वयावयवे वृषलस्य सा
चिव्यं ग्राहयितुं न शक्यते· तदभियोगं प्रति निरुद्योगो वा स्थापयितुमितस्माभिरभियुक्तैर्नयेन बुद्ध्या तपोवनगतो पि घातित प्य
तपस्वी नंदवंश्यः सर्वार्थसिद्धिः। यावदयं मलयकेतुमंगीकृत्यास्मदुच्छेदाय विपुलतरं प्रयत्नमुपदर्शयन्नेव· प्रसहतेवा
काशे लक्ष्यं बध्वा॥ साधु मात्य राक्षस साधु श्रोत्रिय साधु श्रेष्ठ मंत्रिबृहस्पते साधु कुतः· ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थ स ठ
तः सेवते तं गच्छंत्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया। भर्तुर्ये प्रलयेपि पूर्वसुकृतासंगेन निःसंगया भक्त्या कार्यधुरं
वहंति कृतिनस्ते दुर्लभास्त्वादृशाः॥१४॥ अथवा अत एवास्माकं त्वत्संग्रहे यत्नः कथमसौ वृषलस्य साचिव्यग्रहणे
न सानुग्रहः स्यादिति। कुतः। अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्ते कुतः प्रज्ञाविक्रमशालिनोपि हि भवेत्किं भक्तिही
शि

३ नाफलं तावज्ञातिक मम कर्मः समुदितायेषां गुणाम्नृतयेनेम्नत्वान्नपतेः फलत्रमितेरसंपत्तु तापकुत्सु पात्त तन्नपायस्मि
न्वत्तु निनशपा नेमस्वीयतेप थ्याशक्तिः किं पतेत द्वहरांगप्रतिपलः कथमिति अत्रतावहू फलपर्व तयोरन्नतरविनारेमना पि
वा एकपस्याप रुतं तवती ति विष कन्यया राक्षसेनास्माकमत्पेतोपकारिमि त्तंघातिन स्तपस्वीपर्वत कूडूतिसंचारि
तो ऊगलिजनाय चादः लोक प्रत्यया र्थमस्येवार्थस्यो भिष्यक्रये पितानेचाणाक्येन घा तितङ्रतिरहस्तिज्ञा सपित्तामा थ
ता रा पुरोतो य थाहि नोमलयकेतुःश क्यः खलु मराहसमतिपरिग्रहीतोपि स्तुति ध्यमानः प्रज्ञयानि वारयितुं नपुनरस्यानिग्रहा
स्पर्वतकवधोत्र मयप्रः प्रकाशी भवत्प्रमार्हमिति अत्रान्तरेस्तु निपुणकं अत्र लपरूपरपहयोरतुरकापरकजनानि ज्ञासमा ता६
५न्ना चक्रविधदेशवेषभाषाचारसंचारवेदिनो नानाव्यंजनाः प्रणिधयः अन्विष्यं तेच कुसुमपुरनिवासिनां नेद्यमात्यसुहृदा न्नि५
निपुणं प्रचारगतयः तत्कारणानुत्तायघहेतव्हापत्तामापादितांवद्ढगुप्तसहोत्थायिनो भद्रलटप्रभृतयः प्रधानपुरु
षाः शत्रुप्रयुक्तानां च तीक्ष्णरसदादीनां प्रतिविधानं प्रत्यप्रमादिनः परीक्षितभक्तयः क्षितिपतिप्रत्यासन्ना निरूपिताःसत्ता
म त्रास्मत्सुहृत्पुरुषाः अस्ति चास्माकं सहाध्यायी मित्रमिंदुशर्मा नाम ब्राह्मणः सच औशनस्यां दंडनीत्यां चतुःषष्ठ्यंगे ज्योतिः
शास्त्रे परं प्रावीण्यमुपगतः सचमया क्षपणकलिंगधारी नंदवंशवधप्रतिज्ञानंतरमेव कुसुमपुरमुपनीय सर्वनंदामा रा म·
३

ॐ३

स्यैः सहसख्यमुत्पादितो विशेषतस्तस्मिन्राक्षसः समुत्पन्नविस्रंभस्तेनेदानीं बहुप्रयोजनमनुष्ठेयं भविष्यतीति। तदेवमस्मत्तो
न किंचित्परिहास्यते। वृषलएव केवलं प्रधानप्रकृतिरस्माभिरारोपिततंत्रभारः सततमुदास्ते। अथवा यत्स्वयमभियो
गदुःखैरसाधारणैरपाक्रियते तदेव राज्यं सुखयति। कुतः स्वयमाहृत्य भुंजाना बलिनोपि स्वभावतः। नरेंद्राश्च मृगेंद्राश्च प्रा
यः सीदंति दुःखिताः॥२१॥ ततः प्रविशति यमपटेन चरः। चरः णमह जमस्स चलणे किं कज्जं देवएहिं अण्णेहिं। ए
सो क्खु अण्णभत्ताणं हरइ जीअं चडफडंतं॥२२॥ अवि अ। पुरिसस्स जीविदव्वं विसमादो होइ भत्तिगहिआदो। मारेइ सव्वलो
अं जो तेण जमेण जीआमो॥२३॥ जाव एदं गेहं। पविसिअ जमपडं दंसअंतो गीआइं गाएमि। परिक्रामति। शिष्यः विलोक्य। भद्र न
द्वितीयं ५ गे प्रवेष्टव्यम्। चरः हं भो बह्मण कस्स एदं गेहं। शिष्यः अस्माकमुपाध्यायस्य सुगृहीतनाम्न आर्यचाणक्यस्य। चरः विहस्य। हंहो वंभण
आर्या यस ४ भत्ताणं अत्तणो केरअस्स ज्जेव धम्मभादुअस्स घरं। ता देहि मे पवेसं जाव दे उवज्झायस्स धम्मं उवदिसामि। शिष्यः
सक्रोधं धिङ्मूर्ख किं भवानस्मदुपाध्यायादपि धर्मवित्तरः। चरः हंहो वंभण मा कुप्प ण सव्वो सव्वं जाणादि। ता किंपि तुह उव
ज्झाओ जाणादि किंपि अम्हारिसा वि जाणंति। शिष्यः सक्रोधं धिङ्मूर्ख सर्वज्ञतामुपाध्यायस्यापहर्तुमिच्छसि। चरः हंहो वं
म्हण जइ तुह उवज्झाओ सव्वं जाणादि ता जाणादु दाव केसं चंदो अणभिप्पेदो त्ति। अविअ। कमलाणं मणहराणं वि रूवादितो विसं
शिष्यः मूर्ख गुरोः किमनेन ज्ञातेनाज्ञातेन वा। जेव्व दे जाणिस्सदि जं तुमं सि णाणं जाणासि देसा मोदिं तमं दाव दत्ति अं जाणासि कमलाणं चंदो अणभिप्पेदो त्ति। १
आ तु नि चरः हंहो बह्मण उवज्झाओ ज्जे॥

५ वद्इसीलं। संघुस्समंडलम्मिं विज्जाइंवं दैविरुद्धाइं। श्वाराण। आकर्ण्यआत्मगतं· पुंद्रगुप्तापरक्रान्तुरुपात्रज्जा नामीतुपद्दिसमते
नः शिग्मूरविनकिल्लि दमसंवद्दमभिधीयते· वरः। हंहो बम्हराण सुसंवइंजेवमेवे· सि· पद्दिकिंस्यात्· च· जइस्तुरिट्टंजा रागंत
मंलहो चाराण। भद्दविम्मडं प्रविश· लस्प सेम्प्रोनारंज्ञानादंच· चः एसोपविसामि· प्रविश्यापस्ट्टत्य च· ज अद्दंश अज्जो वाराणस्य·
विलोक्यात्मगतं· कथंप्रभ्रष्टतत्त्वात्कार्याणां कस्यपरिज्ञानितिमुक्तो निपुणाक इति नज्ञायते। आः ज्ञातं। अयंकयं प्रकृतिवि
ज्ञातानेनि सुक्को निपुणकः। प्रकाशं· भद्रस्वागतं· उपविश्यतां। चरः· जं अज्जो आणवेदिं ति भूमावुपविशति· चाण। भद्दकरी
येदाणीसुणिपोगद्दत्तांतं· अपिवव्हलमनुरक्ताः प्रकृतयः। चरः। अथइं अज्जेणणेसुडिनेसुवेराअकारणेस्तु परिद्दरिक्रतेस्तुसुणि
"६ उत्तंदट" हीदराणमधे अंचंदम्मसउरत्ता अपकिदीओ किंतिउणा असंमहिद्दिएत्थ णअरेअमच्चरक्खसेणपट्टमंससुप्पसरिरो हदक
माणतिसिडुरि सोजेदेवस्सचंदसिरिणोसिरिंणसहंति। चाराण। सक्रोधं नन्वात्मजीवितं न सहंत इति। भद्र अपिज्ञायं
तेनामधेयतः। चरः। अज्जंकइं अमुणिअं राणमहेज्जा अज्जस्सणिवेदीअंतिच्चाण। तेनदि ओ हमिच्छामि। चरः। सुणादु अज्ज तेओ
पहुमंदा वअज्जस्सारिडंपकेरुवड्डपकच्चवादोरवद्दणअओ। चाण· सहर्षमात्मगतं· प्रकाशं· अस्मद्द्विषुपदे वद्ध पक्षप तं
पातः। रूपराकः। चरः। जीवसिद्धीणाम जो रासांअमच्चरक्खसपउत्ताविसकेसादेवेपद्धदीसरेसमावेसितो· चाणक्यः स्वगतं राम· ५

हीं ४

जीवसिद्धिस्तावदस्माकं प्रणिधिः। प्रकाशं भद्र अथ्यापरकः। चरः। अत्थअज्जेअवरो विअमच्चरक्खसस्स पिअवअस्सो काअत्थोसंअडदा
सो णाम। चाराण। विहस्यात्मगतं कायस्थः कायस्थ इति लघ्वी मात्रा तथापि न युक्तं प्राकृतमपि रिपुमवज्ञातुं। तस्मिन्मया सु पर२
हृत्त्वव्याजेन सिद्धार्थको निक्षिप्तः। प्रकाशं भद्र तृतीयमपि श्रोतुमिच्छामि। चरः। तदिओअमच्चरक्खसस्स दुदीयं हिअअं हिअ
४ चत्तु अ पुप्फडरणिवासी मणिआरसेट्ठी चंदणदासो णाम जस्स घरे कलत्तं णासीकदुअ अमच्चरक्खसो णअरादो अवक्कतो। चा
णा आत्मगतं। नूनं सुहृत्तमो न ह्यनात्मसदृशेषु राक्षसः कलत्रं न्यासीकरिष्यति। प्रकाशं। भद्र चंदनदासस्य गेहे राक्षसेनक
लत्रं न्यासीकृतमिति कथमवगम्यते। चरः। अज्ज इअं अंगुलिमुद्दा संवदिअ अवगमइस्सदि त्ति मुद्दां समर्पयति। चाराण। गृ
६ क्त हीत्वा वाचयति नाम गृहीत्वा सहर्षमात्मगतं ननु वक्तव्यं राक्षस एवायमस्मदंगुलिप्रणयी संवृत्त इति। प्रकाशं भद्र अंगुलिमु
५ मिछा द्राधिगमं विस्तरेण श्रोतुमिच्छामि। चरः। सुणादु अज्जो अत्थि दाव अहं अज्जेण णिओइदो इमस्स णअरस्स रप्पवेसे अ संक
णीए सांइम्मि णाजमवडे रा अ हिंडंतो अ ज्जेमणिआरसेट्ठिचंदणदासस्स गेहंपविट्ठो म्हि जमपडं पसारिअ पउत्तो म्हि गाइदुं ता
णा तमस्सलतः। चरः। तदो एक्को दारओ पंचवरिसदेसीओ पिअदंसणो कुमारओ बालजणसुलहकोदूह ९२
२फु लुप्फुरिअणअणो णिग्गन्तुं पउत्तो [illegible] इत्थिआमुहीए एक्काए दारएहिं अत्थि आए सो कुमा
४ हालिगा होरिति संकापरिणाहे णिक्कमिअ गरू अंगरूअोस्सलाजेवं अवतरस्सतं उत्थिआ उणस्स उक्खिदो मह तोकलम्म लो· ता ४१

ह्रि६ तै१ रंदेस घा१

५ रोसिणिक्कमंतो जेव रोसिं ब्रुढिमण्ववलं विबोको मलाए वाकुलदिआए जिस्सा कुमारसं रो हसं भमंदलि अं उली आदो करादो दुरि संगु
लिंपरिणाहं विघाडिआ विअलिआ मुद्दिआ साअं रेहली वंदेहि वडिअं इत्थि आपरीए अराव बुद्धा जेत्र महं चलणवा संगदा
समभाविद्धि अं पणाम णिक्कडिआ णं वं बक्कुहरिणिद्धलासं वुआ मए विअमद्धरकवसस्संणमं किं देत्ति अअस्सपाअं मूलं पा
विरं तारं सोऽमारमुहाए आगमोत्रिं चाणा भइ अमुणमपसर अविसादस्सपरिअमसमअ रूपं कलेपा ~~...~~
~~...~~ अधिगमिपसि चरणजं अज्जो आणावेदित्ति निक्कांतः चाणा णा
ऊं रवं प्रविश्य शिष्यः उपाध्याय आज्ञापय चाणा वत्स मसीपात्रं पत्रं चोपनय शिष्यः यदाज्ञापयत्युपाध्याय इति निष्क्रम्य पुनः प्रवि
श्य उपाध्याय इदं मसीपात्रं पत्रं च चाणा गृहीत्वा स्वगतं किमत्र खिलिखामि अनेन खलु लेखेन राक्षसो जेतव्यः प्रविश्य प्रती
हारी जअदु जअदु अज्जो चाणा सहर्षमात्मगतं गृहीतो मया जयशब्दः प्रकाशं शोणोत्तरे किमागमनकारणं प्रती अज्ज कमलमउला उ
आरं अंजलिं सीसे णिवेसिअ देवो चंदसिरी विण्णवेदि इच्छामि अहं अज्जेण अब्भणुण्णादो देवस्स पव्वदीसरस्स पारलोइअं काउं ति
णाअं धारिआइं आहरणाइं अ बंबाणाणं पडिवादेमि त्ति चाणा सहर्षमात्मगतं साधु वृषल साधु ममैव हृद
येन सह संवादितवानसि स्वगतं प्रकाशं शोणोत्तरे उच्यतामस्मद्वचनाद् वृषलः साधु वत्स साध्वभिहितः वत्स लोकव्यवहाराणामभिज्ञ राम. ५
नु तापूजनीयतामात्मनोभिप्राप्यः किंतु पर्वतेश्वरधृतनपूर्वाणि गुणवंति भूषणानि गुणवद्भ्य एव ब्राह्मणेभ्यः प्रतिपादनीयानि तदहं स्वयं

परीक्षितगुणान् ब्राह्मणानेष प्रेषयामि प्रती जं अज्जो आणवेदि त्ति निष्क्रांता चाणा शार्ङ्गरव उच्यतामस्मद्वचनाद्विश्वावसुप्रभृतयः
स्त्रयो भ्रातरः वृषलाद् आभरणानि प्रतिगृह्य मां द्रष्टव्य इति शार्ङ्ग यदाज्ञापयत्युपाध्याय इति निष्क्रांतः चाणा उत्तरोयं लेखार्थः
पूर्व स्तु कोस्तु विलिख्य आः ज्ञातं उपलब्धवानस्मि प्रणिधिभ्यः यथा तस्य म्लेच्छराजबलस्य मध्यात्प्रधानतमाः पंच राजानः परया सुहृत्त
४या. या राक्षसमनुवर्त्तत इति ते यथा कौलूतश्चित्रवर्मा मलयनरपतिः सिंहनादो नृसिंहः काश्मीरः पुष्कराक्षः क्षतारिपुमहिमा सैंधवः
सिंधुसेनः मेघाख्यः पंचमोस्मिन्पृथुतुरगबलः पारसीकाधिराजो नामान्येषां लिखामि ध्रुवमहमधुना चित्रगुप्तः प्रमार्ष्टु परम्य वा
लिखामि सर्वे मे वा नमिव्यक्तं तावदास्तां शार्ङ्ग रव प्रविश्य शिष्यः उपाध्याय आज्ञापय चाणा वत्स श्रोत्रियक्षराणि प्रयत्नलिखितान्यपि
णि प्रथमतो पि नियतमस्फुटानि भवंति तदुच्यतामस्मद्वचनात् सिद्धार्थकः एनं शकटदासेन केनापि कस्यापि स्वयं वाच्य
मित्यदत्तबाह्यनामानं लेखं लेखयित्वा मामुपतिष्ठस्व न चाख्येयमस्मै चाणक्यो लेखयतीति शिष्यः यदाज्ञापयत्युपाध्याय इ
ति निष्क्रांतः चाणा स्वगतं हंत जितो मलयकेतुः प्रविश्य लेखहस्तः सिद्धार्थकः जअदु जअदु अज्जो अज्ज अअं सो सअडदासेण स
हत्थलिहिदो लेहो चाणा गृहीत्वा हंत दर्शनीयान्यक्षराणि इत्यनुवाच्य भद्र अनया मुद्रया मुद्रयैनं सिद्धा जं अज्जो आणवे
दित्ति तथा कृत्वा अज्ज मुद्दिओ लेहो ता आणावेदु अज्जो किं अवरं अणुचिट्ठीयदु त्ति चाणा कस्यं भद्र कस्मिंश्चिदाप्तजनानुष्ठेये क

६ मैत्रीं त्वां व्यापारयितुमिच्छामि॰ सिद्धा॰ सहर्षं अज्ज गिहिदो म्हि। ता आणावेदु अज्जो इमिणा दासजणेण अणचिट्ठिदव्वं॰ चाण॰ प्रथमं तावद् हि२
वध्यस्थानं गत्वा घातकाः सरोषं दक्षिणाक्षिसंकोचसंज्ञां ग्राहयितव्याः ततस्तेषु गृहीतसंज्ञेषु भयापदेशापसारितेषु ततः प्रद्रुतेषु
शकटदासो वध्यस्थानादपनीय राक्षसं प्रापयितव्यः तस्माच्च सुहृत्प्राणरक्षणपरितुष्टात्पारितोषिकं याचयित्वा राक्षसः एवं किंचि
४पु त्कालं सेवितव्यः ततः प्रत्यासन्नेषु परेषु प्रयोजनमिदमनुष्ठेयं॰ करणीयं॰ एवमेवं॰ सिद्धा॰ जं अज्जो आणावेदित्ति निष्क्रांतः॰ चाण॰
शार्ङ्गरव॰ प्रविश्य शिष्यः आज्ञापयतूपाध्यायः॰ चाणक्यः॰ उच्यतामस्मद्वचनात्कालपाशिको दंडपाशिकश्च॰ ह
षलः समाज्ञापयति य एष क्षपणको जीवसिद्धिः राक्षसप्रयुक्तो विषकन्यया पर्वतेश्वरं घातितवानिति एनमेव दोषं प्रख्याप्य स
निकारं नगरान्निर्वास्यतामिति॰ शिष्यः यदाज्ञापयत्युपाध्याय इति निष्क्रामति॰ चाण॰ तिष्ठ श्रूयतामपरः कायस्थः शकटदासो ना
म राक्षसप्रयुक्तो नित्यमस्मच्छरीरमभिद्रोग्धुमिह प्रयतते स एनमेव दोषं प्रख्याप्य शूलमारोप्यतां गृहजनश्चास्य बंधनागा
रं प्रवेश्यतामिति॰ शिष्यः यदाज्ञापयत्युपाध्याय इति निष्क्रांतः॰ चाण॰ चिंतां नाटयित्वा अपि नाम दुरात्मा राक्षसो गृह्येत॰ प्रवि
श्य सिद्धार्थकः अज्ज गहिदो॰ चाण॰ सहर्षमात्मगतं हंत गृहीतो राक्षसः॰ प्रकाशं अहो कोयं गृहीतः॰ सिद्धा॰ गहिदो अज्जस्स
संदेसो॰ ता गमिस्सं कज्जसिद्धीए॰ चाण॰ सांगुलिमुद्रं लेखं समर्पयित्वा भद्र सिद्धार्थक गम्यतामस्तु ते कार्यसिद्धिः॰ सिद्धा॰ जं अज्जो आ राम॰

तः२ ६

णावेदित्ति निष्क्रांतः॰ ततः प्रविशति शिष्यः॰ शिष्यः॰ उपाध्याय कालपाशिको दंडपाशिकश्च उपाध्यायं विज्ञापयतः इदमनुष्ठीयते देवस्य चंद्र
गुप्तस्य शासनमिति॰ चाण॰ शोभनं वत्स मणिकारश्रेष्ठिनं चंदनदासमिदानीं द्रष्टुमिच्छामि॰ शिष्यः यदाज्ञापयत्युपाध्याय इति
निष्क्रम्य चंदनदासेन सह पुनः प्रविश्य इत इतः श्रेष्ठिन्॰ चंदनदासः॰ आत्मगतं॰ चाणक्कम्मि अकरुणे सहसा सद्दाविअस्स वि जणस्स
॥ णिद्दोसस्स वि संका किं उण संजाददोसस्स॥२॥ ता भणिदा मए धरणसेणप्पमुहा णिअघरवासिणो अज्ज राजहा कदा वि चाणक्को
मह गेहं विविचिस्सदि ता णिउणं भट्टिणो अमच्चरक्खसस्स कलत्तं मए दाणिं उवहाविदं णिव्वुदि॰ शिष्यः इत इतः श्रेष्ठिन्॰ चंद
न॰ अयं आअच्छामि॰ उभौ परिक्रामतः॰ शिष्यः उपाध्याय अयं श्रेष्ठी चंदनदासः॰ चंद॰ अज्ज अज्जो॰ चाण॰ नाट्येनावलोक्य
भो श्रेष्ठिन् स्वागतमिदमासनमास्यतां॰ चंद॰ किं ण जाणादि अज्जो जहा अणुचिदो उवआरो परिहवादो वि दुक्खमुप्पादेदि ता इह
के उचिदाए भूमीए उवविसामि॰ चाण॰ श्रेष्ठिन् न युज्यते एवमस्मद्विधेभ्य तत्र उपविश्यतामासनमेव॰ चंदन॰ जं
अज्जो आणावेदित्ति उपविश्य स्वगतं उवक्खित्तं अणेण किं पि॰ चाण॰ भो श्रेष्ठिन् चंदनदास अपि प्रचीयंते संव्यवहारलाभाः॥
चंद॰ स्वगतं॥ अच्चादरो संकणीओ॰ प्रकाशं॰ अध इं॥ अज्जस्स पसाएण अक्खंडिआ वणिज्जा॰ चाण॰ अपि चंद्रगुप्तदोषा अति
क्रांतपार्थिवगुणानधुना तु स्मारयंति प्रकृतीः॥ चंद॰ कर्णौ पिधाय॰ संतं पावं॥ सरअणिसासमुग्गएण व पुण्णिमासीचंदेण चंद

मु२

१ सिरि राणं अहिणंदंति पाकिदीओ। चाणा। भो श्रेष्ठिन् प्रयोधरेण प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छंति राजानः। चंद। आणावेदु अज्जो किं कित्तिअं
चाअ त्थीअदि मा दाव जणेण हेइ त्ती अदि। चाणा। भो श्रेष्ठिन् चंदनदास चंद्रगुप्त राज्यमिदं न नंदराज्यमिदं यतो नंदस्यैवार्थरुचेरर्थसं
बंधः प्रीतिमुत्पादयति चंद्रगुप्तस्य तु भवतामपरिक्लेश एव। अर्थरुचेरर्थसंबंधः प्रीतिमुत्पादयति
चंद्रगुप्तस्य तु भवतामपरिक्लेश एव। चंद। हर्षं अज्ज अणुगिहिदम्हि। चाणा। भो भो श्रेष्ठिन् स चापरिक्लेशः कथमाविर्भवतीति न
नु प्रष्टव्याः स्मस्तत्र भवता। चंद। आणावेदु अज्जो। चाणा। संक्षेपतो राजन्यविरुद्धाभिर्वृत्तिभिर्वर्तितव्यं। चंद। अज्ज को अधण्णो अज्जे
५ ण राएण विरुद्धो त्ति अवगम्मदि। चाणा। प्रथमं तावद्भवानेव। चंद। कण्णेहिं पिधाय संतं पावं किरि सो राएण सह विरोहो गि ८
। चाणा। अयमीदृशो विरोधो यत्त्वमद्यापि राजापथ्यकारिणो राक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि। चंद। अज्ज अलीअं
केण विणिवेदिदं अज्जस्स। चाणा। भोः श्रेष्ठिन् अलमाशंकया। भीताः पूर्वराजपुरुषाः पौराणा
मनिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशांतरं व्रजंतीति। तत्प्रच्छादनं तु दोषमुत्पादयति। चंद। एवं णेदं तस्सिं समए आसि
अम्ह घरे अमच्चरक्खसस्स घरजणो त्ति। चाणा। पूर्वमनृतमिदानीमासीदिति परस्परविरुद्धे वचने। चंद। एत्तिअं अत्थि मे वा
अच्छलं। चाणा। भो श्रेष्ठिन् अशंकितः चंद्रगुप्ते राजन्यपरिग्रहच्छलानां तत्समर्पय राक्षसस्य गृहजनं अच्छलं भवतु। चंद। अज्ज राम० १

६तं १

ई अमच्चरे

णं विण्णवेमि आसि तस्सिं समए अमच्चरक्खसस्स घरजणो त्ति। चाणा। अथेदानीं क्व गतः। चंद। ण आणामि को कहिं गदो त्ति। चाणा
णा। कथं न ज्ञायते नाम। शिरसि भयमतिदूरे प्रतीकारः। यतः उवरि घणं घणरावडलं दूरे दइआ किमेतदावडिअं। हिमवदि दि
उह्र व्वोसहीओ सीसे सप्पो समाविट्ठो। अन्यच्च आनंदमिव विष्णुगुप्तः केल जाणाहि चंद्रगुप्तममात्यराक्षसः समुच्छेत्स्य
तीति मैवं मंस्थाः। पश्य। विक्रांतैर्नयशालिभिः सुसचिवैः श्रीर्वक्रनासादिभिर्नंदे जीवति या तदा न गमिता स्थैर्यं चलंती मुहुः। ता
मेकत्वमुपागतां द्युतिमिव प्रह्लादयंतीं जगत्कश्चंद्रादिव चंद्रगुप्तनृपतेः कर्तुं व्यवस्येत्पृथक्॥२४॥ अपि च। आस्वादितद्विरद
शोणितशोणशोभां संध्यारुणामिव कलां शशलांछनस्य। जृंभाविदारितमुखस्य मुखात्स्फुरंतीं को हर्तुमिच्छति हरेः परिभूय दंष्ट्रां
॥२५॥ चंद। सुगंधं फलेण संपादिदं सो हु दिट्ठेवि कण्ठिदं। ततो नेपथ्ये उत्सारणा क्रियते। चाणा। शार्ङ्गरव ज्ञायतां किमेतदिति। शि
ष्यः यदाज्ञापयत्युपाध्याय इति निष्क्रम्य पुनः प्रविश्य उपाध्याय स एष राजापथ्यकारी क्षपणको जी
वसिद्धिः सनिकारं नगरान्निर्वास्यते। चाणा। क्षपणकः अहह अथवा अनुभवतु राजापथ्यकारित्वस्य फलं। श्रेष्ठिन् चंदनदास
एवमयं राजा पथ्यकारिषु तीक्ष्णदंडः क्रियतां पथ्यं सुहृद्वचनमनुतिष्ठ येन तो विदितो राजप्रसादः। चंद। अज्ज गेहे संते विण्ण
सममेव मि कुणे अज्ज अस्संतं सममं आदिं। ततो नेपथ्ये कलकलः। चाणा। शार्ङ्गरव ज्ञायतां किमेतदिति। शिष्यः यदाज्ञापयत्युपाध्याय

१ऊदो प्पीर

चंदनदास एष ते निश्चयः। चंद। बाढं। एसो। थिरो मे। णिच्छओ। चाण। आत्मगतं साधु

८ इति निष्क्रम्य पुनः प्रविश्य उपाध्याय अयमसौ कायस्थः शकटदासः शूलमारोपयितुं नीयते। चाण। स्वकर्मफलमुपभुंक्तां। भो
श्रेष्ठिन् चंदनदास एवमपथ्यकारिषु तीक्ष्णदंडो राजा न मर्षयिष्यति राक्षसकलत्रप्रच्छादनं। तदस्मात् परकलत्रेणात्मनः
कलत्रं जीवितं च। चंद। अज्ज किं मे भअं दावेसि संतं पि अहं अमच्चरक्खसस्स घरअणं ण समप्पेमि किं उण असंतं। चाण। चंद
नदास साधु। सुलभेष्वर्थलाभेषु परसंवेदने जने। क इदं दुष्करं कुर्यादिदानीं शिबिना विना। शब्दप्रकाशं। चंदनदास एष ते
निश्चयः। चंद। बाढं। एस थिरो णिच्छओ। चाण। सक्रोधं। दुरात्मन् दुष्टवणिक् अनुभूयतां तर्हि नरपतेः क्रोधः। चंद। एस सज्जो
म्हि। अणुचिट्ठदु अज्जो अत्तणो अहिआरसरिसं। चाण। शार्ङ्गरव उच्यतामस्मद्वचनात् कालपाशिको दंडपाशिकश्च शीघ्रमयं
त दुष्टवणिक् अथवा तिष्ठतु उच्यतामस्मद्वचनात् दुर्गपालो विजयः गृहीतगृहसारमेनं सपुत्रकलत्रं रक्ष तावद्यावद्वृषलाय क
थ्यते स एवास्य प्राणहरं दंडमाज्ञापयिष्यति। शिष्यः। यदाज्ञापयत्युपाध्याय इति। श्रेष्ठिन् इत इतः। चंद। अज्ज अअं आगच्छामि।
उद्वि आत्मगतं। दिष्टिआ मित्तकज्जेण मे विणासो ण पुरिसदोसेण। परिक्रम्य शिष्येण सह निष्क्रांतः। चाण। सहर्षं हंत लब्ध इदानीं
राक्षसः। त्यजत्यप्रियवत्प्राणान् यथा तस्यायमापदि। तथैवास्यापदि प्राणा नूनं तस्यापि न प्रियाः।१४। नेपथ्ये कलकलः। चाण।
शार्ङ्गरव। प्रविश्य शिष्यः उपाध्याय आज्ञापय। चाण। वत्स किमेष कलकलः। शिष्यः। विभाव्य उपाध्याय एष खलु शकटदास राम. ८

वध्यभूमेरादाय समपक्रांतः सिद्धार्थकः। चाण। स्वगतं। साधु सिद्धार्थक कृतः प्रारंभः। प्रकाशं। सत्यं किमपक्रांतः। सक्रोधं वत्स उच्यतां भा
गुरायणः यथा त्वरितं संधावयेति। शिष्यः निष्क्रम्य पुनः प्रविश्य उपाध्याय धिक् कष्टं अपक्रांतो भागुरायणः। चाण। आत्मगतं
व्रजतु कार्यसिद्धये। प्रकाशं सक्रोधं वत्स उच्यतामस्मद्वचनात् भद्रभटपुरुषदत्तडिंगिरातबलगुप्तराजसेनलोहिताक्षविज
यवर्माणः शीघ्रमनुसृत्य गृह्यतां दुरात्मा भागुरायण इति। शिष्यः यदाज्ञापयत्युपाध्याय इति निष्क्रम्य पुनः प्रविश्य सविषा
दं उपाध्याय हा धिक् कष्टं सर्वमेव तंत्रमाकुलीभूतं तेपि खलु भद्रभटप्रभृतयः प्रथमतरमप्रभातायामेव रजन्यामपक्रांताः
चाण। आत्मगतं। सर्वथा शिवाः पंथानः संतु। प्रकाशं। वत्स अलं विषादेन। पश्य। ये याताः किमपि प्रधार्य हृदये पूर्वं गता ए
व ते ये तिष्ठंति भवंतु तेपि गमने कामं प्रकामोद्यताः। एका केवलमेव साधनविधौ सेनाशतेभ्योधिका नंदोन्मूलनदृष्टवीर्य
४ गा महिमा बुद्धिस्तु मा गान्मम।१४। उत्थाय एष दुरात्मनो भद्रभटप्रभृतीनाहरिष्यामि। आत्मगतं। दुरात्मन् राक्षस क्व यास्यसि।
एषोहमचिराद्भवंतं। स्वच्छंदमेकचरमुज्ज्वलदानशक्तिमुत्सेकिना बलमदेन विगाहमानं। बुद्ध्या निगृह्य वृषलस्य कृते क्रि
यायामारण्यकं गजमिव प्रगुणीकरोमि।१५। इति निष्क्रांताः सर्वे। प्रथमोंकः। ततः प्रविशत्याहितुंडिकः। आहि। जाणंति तंतजु
त्तिं जहट्ठिअं मंडलं अहिलिहंति। जे मंतरक्खणपरा ते सप्पणराहिवे उवअरंति।१। आका
हि

किं न भणासि राअं अऊलसेव अओत्ति॰ एणं ... रखेन्न दिजेदि अज्जो र
जीव

९ रो अज्ज॰ किं भणासि को दुमं जित्र अज्ज हरेदु आहितुंडिओ जिस्सवि सोराणम॰ किं भणासि अहं विअ आहितुंडिअरेद लिंडु दच्छामित्ति अ

धं केदरं। विन्नि अज्ञा जीवदि अज्जो अहिरोग॰ कांपेदि॰ अमे तोस हिंकुसलोवा लमाही॰ पवत्तमित्र गअवरा रेहेणा॰ लद्धा धि ओरो

अनिरपेक्षः जिअ कासी राअसेवकोत्ति तदो जेव्ह एदंति सिग्धु रिसा अवदुस्सो विराम संअसदृहवेदित्ति। अए अदि दंतो पुनरप्पाकारो॰ अ

ज्जोतु मं उण किं भणासि॰ किं एदं संदेपडालसमुण एसवृत्तिं॰ अज्जो विअ जीअ ... संपादअआसप्पा॰ किं भणासि अहिछिपकिरदु इंवा

म मेत्तिअ। पसीददु अज्जो अज्ञा रांक्सवुरदंतो जइकोदूहलं ताए हिएद सिंअ आवासे यविसिअ अंदं से मि॰ किं भणासि एदं खु महि

रो अमदक्खुरकुसलत्तो गहरगं त्ति अम्हारिसाणं इह पवेसो त्ति राग छदु अज्जो जीवि आरंपसार राअत्तिं मे पवेसो त्ति॰ काथं र

सो विआदि दंतोत्सगते अपरि आसंस्कृतमाश्रित्य॰ चाणक्यमतिपरिगृहीतं चंद्रगुप्तमवेक्ष्य सिफलमिव राक्षसप्रयत्नमवग

च्छामि। राक्षसमतिपरिगृहीतं मलयकेतुमेवेद राज्याच्चलितमिव चंद्रगुप्तमवगच्छामि कुतः कौटिल्यधीरज्जुनिबद्धमूर्तिम

मे न्यो स्थिरां मौर्यकुलस्य लक्ष्मी। उपायहस्तैरिव राक्षसेन निकृष्यमाणामिह लक्षयामि।२। तदेवमनयोर्बुद्धिशालिनोः सुसचि

वयोर्विरोधे संशयितेव नंदकुललक्ष्मीलिंगते॰ कुतः। विरुद्धयोर्भृशमिह मंत्रिमुख्ययोर्महावने वनगजयोरिवांतरे। अनि राम॰

रिवांतरे अनिश्चयाद्गजवशयेव भीतया गतागतैर्ध्रुवमिह खिद्यते श्रिया।३। तयाव दहममात्यराक्षसमेव गच्छामि तत्प्रविश्यास्ता ९

स नस्थः पुरुषेणानुगम्यमानः स्वभवनगतः सचिंतो राक्षसः सशवाष्पकंठं कष्टं भोः कष्टं। वृष्णीनामिव नीतिविक्रमगुणव्यापा अमी र

व्यापारशांतद्विषां नंदानां विपुले कुलेऽकरुणया नीते नियत्या क्षयं। चिंतावेशसमाकुलेन मनसा रात्रिंदिवं जाग्रतः सैवेयं

मम चित्रकर्मरचना भित्तिं विना वर्तते।४। अथवा नेदं विस्मृतभक्तिना न विषयव्यासंगमूढात्मना प्राणप्रच्युतिभीरुणा

न च मया नात्मप्रतिष्ठार्थिना। अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते देवः स्वर्गगतोपि शात्रववधेनाराधितः स्यादिति

।५। आकाशमवलोक्य सास्रं भगवति कमलालये भृशमगुणज्ञासि। कुतः आनंदहेतुमपि देवमपास्य नंदं सक्तासि किं कथय

६ पु वैरिणि मौर्यपुत्रे दानांबुराजिरिव गंधगजस्य नाशे तत्रैव किं न चपले प्रलयं गतासि।६। अपि चानभिजाते पृथिव्यां किं दग्धाः

५ह प्रथितकुलजा भूमिपतयः पतिं पापे मौर्यं यदसि कुलहीनं वृतवती। प्रकृत्या वा काशप्रभवकुसुमप्रांतचपला पुरंध्रीणां प्र

ज्ञा पुरुषगुणविज्ञानविमुखी।७। अपि चाविनीते तदहमाश्रयोन्मूलनेनैव त्वामकामां करोमि। विचिंत्य मया तावत्सु

हृत्तमस्य चंदनदासस्य गेहे गृहजनं निक्षिप्य नगरान्निर्गच्छता न्याय्यमनुष्ठितं किं कारणमिति कुसुमपुराभियोगं प्रत्यनुदासी

नो राक्षस इति तत्रस्थानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोत्ती दणरसदादीनामुपसंग्रहार्थं परकृत्योपजापे

य हार्थं च महता कोशसंचयेन स्थापितः शकटदासः प्रतिक्षणमरातिवृत्तांतोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सु

हणार

नोद्यमः शिथिलीभविष्यति। चंद्रगुप्तशरीरमभिद्रोग्धुमस्माभिः प्रयुक्तानां र

हृदोजीवसिद्धिप्रमत्तयः तात्किमत्र वक्तव्यं । इष्टात्मजस्य प्रदिशान्त्वम एव देवः शार्दूलपोतमिवमं परिपुष्य नष्टः ततोसेव वत्स द्विविधि
१० रत्न खिनभिनत्त्रिमर्मवर्मा [illegible] वे घटितेदेव मत्स्यमत्स्यमार्गं ॥ ततः प्रविशति कंचुकी श्कामं नेदं मि वप्रमण्यजरपाचा राजपुरी
त्रायथाधर्मो मौर्य इव केमेरा नगरे नीतः प्रतिष्ठां मपि । तं संप्रत्युपचीयमानमपि मे लक्ष्यांतरंसे वपालो भोर हसव ज्ञौका यो
यपत्ततेजेलुं नष्टाकोजिता ॥ परिक्रम्योपसृत्य च इदममात्यराक्षसस्य च हृदयावक्त्रविधामि प्रविश्य विलोक्य च स्वस्तिभवते
राक्ष. आर्य जाजले त्वभिवादये । प्रियंवदक आसनं अत्रभवतः । पुरुषः एवं आसनं उपविस इत्युपविष्टः कंचुकी नाघेनोपवि
शति । राक्ष. किमागमन प्रयोजनं । कंचु. अमात्य मलयकेतुरमात्यं विज्ञापयति चिरात्प्रभृति परित्यक्तोचितसंस्कार
त्रिपीड्यतेमे हृदयं । यद्यपि स्वामिगुणाः सहसा न शक्यंते विस्मर्तुं तथापि महिदर्पणं मामानयत्वार्य इत्याभरणं शरीरादवतार्य
कुमारेणाप्रेषितं धारयितुमर्हत्यार्यः । राक्ष. आर्य जाजले विज्ञाप्यतामस्मद्वचनात्कुमारः विस्मृतास्मि भवद्गुणापक्षपाते
न स्वामिगुणाः । किंतु न तावन्निर्वीर्यैः परपरिभवाक्रान्तिकृपणैरोर्वहोम्यंगैरेभिः प्रतनुमपि संस्काररचनां मया वन्निर्मि
त कृपितरितु चक्रस्य निहितं सुगांगेहे मां कांचवरनव सिंहासनमिदं ॥१॥ कंचु. अमात्य अमात्यपनेतरि सुलभमेतत्कु
मारेरात त्वरितमन्यतां कुमारस्य प्रथमः प्रणायः । राक्ष. आर्य कुमारादयनतिमिक्रमणीय वचनो मे भवान् अपि न रक्तुष्टा य राम. १०

प्य
ते कुमारस्या कंचु नाद्येनमपरागानिपरिवाप्य स्वस्ति भवते । राक्ष. अभिवादयाम्यहं । कंचुकी निष्क्रांतः । राक्षसः प्रियंवदकस्ताय
तो कोस्मद्दर्शनार्थी द्वारे तिष्ठति । पुरुषः जं अज्जो आणावेदित्ति निष्क्रम्य आहितुंडिकं दृष्ट्वा भद्द को तुमंत्ति । आहि. भद्द अ
हं खु आहितुंडिओ जिण्णविसो णाम अमच्चस्स पुरदो सप्पेहिं खेलिदुं इच्छामि । पुरु. चिट्ठ दाव जाव अमच्चस्स णिवेदेमि । राक्षसमुपसृत्य अमच्च हु र
खु एसो क्खु सप्पजीवी दुवारे चिट्ठदि सप्पेहिं खेलिदुं । राक्ष. वामाक्षिस्पंदनं सूचयित्वात्मगतं कथं प्रातरेव सर्पदर्शनं । प्रकाशं
ष्य प्रियंवदक न नः कौतुहलं सर्पदर्शने अलः परितोष्य विसर्जयैनं । पुरु. जं अज्जो आणावेदित्ति निष्क्रम्य आहितुंडिकमु
पसृत्य अज्ज एसो अम्हं सरोणफलेण अमच्चो पसादं करेदि गाउणं दंसणेणं । आहि. भद्द विसण्णवेहि भद्द अरोणा अमच्चं
केवलं सप्पजीवी पाउअके दीखु अहं जं इम सब्बं दंसणेण अमच्चो पसादं करेदि ताए दंपत्तं वाचेदुत्ति । पुरु. राक्षसमु
पसृत्य अमच्च एसो खु आहितुंडिओ अमच्चं विण्णवेदि । राक्षसेवलं सप्पेहं पत्तं वाचि अपसीदइत्ति । राक्ष. पत्रं वाचयति । पा
उ शीरास्वसे संकुसमरसं अन्तरेणकुसलदाएं जं उगिरे इममरोतं अस्मरणं कुराउक ॥११॥ राक्ष. आत्मगतं अये कु
सुमपुरवृत्तांतज्ञोहं त्वत्प्रणिधिरयं इति गाथार्थः कार्यव्यग्रत्वान्मनसः प्रभूतत्वाच्च प्रणिधीनां इदानीं स्मृतिरुपलब्धा । वा ध्या
कुमाहितुंडिक इमनाविराधगुप्तेनानेन भवितव्यं । प्रकाशं प्रियंवदकः प्रवेशयैनं सुकविरेष श्रोतव्यमस्मात्सुभाषितं । पुरुषः

११ जंगममवेशाः आरामे चैनिनिष्क्राम्य आहितुंडिकस्तुपसर्पतस्तडवसप्य इत्यङ्गे। आहि। नाघेनोपसर्प विलोकयामागतं अपेअप
ममात्य राक्षसः। भामाव्याकुलत्वं निवेशपशिथिलं कंठेविवृत्यान नात्यकं खेदहिरणावलाविहितयाभिर्यंकोपन्नेत्यामुकुं ॥ पंर
गाढालिंगनसंगपीडितमुरस्थपस्यो ममांशं किरीमोर्मस्योरसिनाधुनापि कुरुते वामेतरं श्रीः स्तनं। २३ प्रकाशं जयत्विद्रु रश्र
मत्रो। राक्षः। विलोक्य अये विराधगुप्तः इत्यर्द्धोक्ते विरूढ्वमप्रश्नो। प्रियंवदक भुजंगैरिदानीं विनोदयामः। तद्विसृज्यतां मः परि
जनेन अस्त्वमपि सुमध्धिकारमनुष्टं कुरु। जंगममरेशो आरामे दिति सपरिजनो निष्क्रांतः। राक्षसः सखे विराधगुप्त इदमासनउ
पपुरु। मास्यतां। विरा। यदाज्ञापयत्यमात्यइति नाट्येनोपविशति। राक्षः। निर्वर्णप्रहे हादेव पारोपजीविनो जनस्यायमवस्थितिरोदि
ति। विरा। अमात्य अलं शोकेन नातिचिरादमात्यो माननुरागनीममवस्थामारोपयिष्यति। राक्षसः सखे विराधगुप्त वर्णयेदानीं
कुसुमपुरवृत्तान्तं। विरा। अमात्य विस्तीर्णः कुसुमपुरवृत्तान्तः तत्कृतः प्रभृति कथयामि। राक्षः। सखे चंद्रगुप्तस्य नग
रप्रवेशात्प्रभृति अस्मत्प्रयुक्तैस्तीक्ष्णरसदायिभिः किमनुष्ठितमित्यादितः श्रोतुमिच्छामि। विरा। एष कथयामि।
अस्ति तावच्छकयवनकिरातकाम्बोजपारसीकप्रभृतिभिश्चाणक्यमतिपरिगृहीतैश्चंद्रगुप्तपर्वतकबलैरुदधिभिरिव
प्रलयकालचलितसलिलैः समंतादुपरुद्धं कुसुमपुरं। राक्षः। शस्त्रमाकृष्य ससंभ्रमं मयि स्थिते कः कुसुमपुरमुपरो रामः ११

धस्यति। इति वीरकशिप्रमिदानीं। प्राकारं परितः शरासनधरैः क्षिप्रं परिक्षिप्यतां द्वारेषु द्विरदैः प्रतिद्विपघटाभेदक्षमैः स्थीयतां। मु
क्त्वा मृत्युभयं प्रहर्तुमनसः शत्रोर्बले दुर्बले ते निर्यान्तु मया सहैकमनसो येषामभीष्टं यशः। २४। विरा। अमात्य अलमावेगेन
वृत्तमिदं वर्ण्यते। राक्षः। कथं वृत्तमिदं मया पुनर्ज्ञातं स एवायं काल इति कृत्रिमशस्त्रमुत्सृज्य सास्रं हा देव नंद स्मरति ते राक्ष
सः प्रसादानां। यत्र नमत्रकाले। यत्रैषा मेघनीलाचलति गजघटा राक्षसस्तत्र यायादेतत्पारिप्लवांभःस्तुति तुरगबलं धार्यतां राक्ष त्र
सेन। पत्तीनां राक्षसोन्तं नयतु बलमिति प्रेषयन्मह्यमाज्ञामज्ञासीः प्रीतियोगात्स्थितमिव नगरे राक्षसानां सहस्रं। २५। विराधः। ततः
बृ्रुदि स मंतादुपरुद्धं कुसुमपुरमवलोक्य एवं सप्रभृति मरुदुपरोधवैशसमनुपरिखिद्यमानमसहमानेन तस्यामवस्थायां पौरजनापे
क्षया पक्रांते तपोवनाय देवे सर्वार्थसिद्धौ स्वामिविरहात्प्रशिथिलप्रयत्नेषु युष्मद्बलेषु घोषणाव्याघातादिसाहसानुमितान न
गरवासिषु पुनरपि नंदराज्यप्रत्यानयनाय सुरुंगामधिगतेषु युष्मासु चंद्रगुप्तनिधनाय युष्मत्प्रयुक्ते विषकन्यया घाति
ते तपस्विनि पर्वतेश्वरे। राक्षः। सखे पश्याश्चर्यं कर्णेनेव विषांगनैकपुरुषव्यापादिनी रक्षिता हंतुं शक्तिरिवार्जुनं बलवती
यावच्चंद्रगुप्तं मया। सा विष्णोरिव विष्णुगुप्तहतकस्यात्यंतिकश्रेयसे हैडंबेयमिवेत्य पर्वतमुपन्नं तद्वध्यमेवावधीत्। विरा। अ
मात्य दैवस्यात्र कामचारस्तत्किं क्रियतां। राक्षः। ततस्ततः। विरा। ततः पितृवधत्रासादपक्रान्ते कुमारे मलयकेतौ विश्वासितेपर्वतकभ्रा =

१२ न्यातरि वैरोचनके प्रकाशिते चंद्रगुप्तस्य नंदभवनप्रवेशे चाणक्येनादूध्याभिहिताः कुसुमपुरनिवासिनः सर्व एव सूत्र
धाराः सांवत्सरिकादेशाद्धार्द्धरात्रसमये चंद्रगुप्तस्य नंदभवनप्रवेशो भविष्यतीत्यतः पुरद्वारप्रवेशात्प्रभृति संस्क्रियतां
राजभवनमिति। ततः सूत्रधारैरभिहितं आर्यप्रथममेव देवस्य चंद्रगुप्तस्य नंदभवनप्रवेशमुपलभ्य सूत्रधारेण दारुवर्मणा क
नकतोरणन्यासादिभिः संस्कारविशेषैः संस्कृतं राजद्वारमितः किमस्माभिरन्यत्संस्कारमाधेयमिति। ततश्चाणक्यबटुना
अनादिष्टेनैव दारुवर्मणा संस्कृतं राजभवनद्वारमिति परितुष्टेन दारुवर्मणः सुचिरं दाक्ष्यमभिप्रशस्याभिहितं अचिरादस्य
दाक्ष्यस्यानुरूपं दारुवर्मन् फलमधिगमिष्यसीति। राक्षः। सोद्वेगं सखेदं कुतश्चाणक्यबटोः परितोषः अफलमनिष्टफलं वा
ल दारुवर्मणः प्रयत्नमवगच्छामि यदनेन बुद्धिमोहाद्वा राजकार्यानुरोधात् कालमप्रतीक्षमाणेन जनितश्चाणक्यबटोश्चेत
सि बलवान्विकल्पः। ततः २ विराध। ततश्चाणक्यहतकेनानुकूललग्नवशादर्द्धरात्रसमये चंद्रगुप्तस्य नंदभवनप्रवेशो भविष्यती
ति शिल्पिनः पौरांश्च गृहीतार्थान्कृत्वा तस्मिन्नेव क्षणे पर्वतेश्वरभ्रातरं वैरोचनकमेकासने चंद्रगुप्तेन सहोपवेश्य कृतः पृथिवी
ग राज्यार्द्धप्रविभागः। राक्षः। किमतिसृष्टः पर्वतेश्वरभ्रात्रे वैरोचनकाय पूर्वप्रतिश्रुतो राज्यार्द्धप्रविभागः। विरा। अथ किं। राक्षः। नून
गतं नियतमतिधूर्त्तेन वटुना तस्यापि तपस्विनः किमप्युपांशुवधमाकलय्य पर्वतेश्वरविनाशजनितस्यायशसः परिहारार्थं रा.मु.

पु रा १२

मेवालोकप्रसिद्धिरुपरचिता प्रकाशं ततस्ततः विरा। ततः प्रथममेव प्रकाशिते रात्रौ चंद्रगुप्तस्य नंदभवनप्रवेशे कृताभिषेके वै
रोचनके विमलमुक्तामणिगुणपरिक्षेपेण परचितविचित्रपट्टमयवारबाणप्रच्छादितशरीरे मणिमुकुटबद्धनिविडतनिम्ममित
रुचिरतरमौलौ सुरभिकुसुमदामवैकक्षिकावभासितविपुलवक्षःस्थले परिचितैरप्यनभिज्ञायमानाकृतौ चाणक्यह
ग तकादेशाच्चंद्रगुप्तोपवाह्यां चंद्रलेखां नाम वशामारूढे चंद्रगुप्तानुयायिना राजलोकेनानुगम्यमाने नंददेवस्य भवनं प्रवि
शति वैरोचनके युष्मत्प्रयुक्तेन सूत्रधारेण दारुवर्मणा चंद्रगुप्तोयमिति मन्यमानेन वैरोचनकस्योपरि पातनाय सज्जीकृ
तं यंत्रतोरणं। अत्रांतरे निगृहीतवाहनेषु स्थितेषु चंद्रगुप्तानुयायिषु भूमिपालेषु युष्मत्प्रयुक्तेनैव चंद्रगुप्तवधाय निषा
दिना बर्बरकेण कनकदंडिकोत्तर्निहितां वारणस्थितामसियष्टिकामाक्रष्टुकामेन अवलंबिता करेण कनकमयं श्रृंखला
न वलंबिनी कनकदंडिका। राक्षः। उभयोरप्यस्थाने यत्नः। विरा। अथ जघनाभिघाततमुत्तेजितकुमारगजवशा प्ररतिजवनतया गत्यं
तरमारूढवती। प्रथमगत्यनुरोधप्रसारितकलितमुक्तेन प्रभ्रष्टलक्ष्यं यंत्रतोरणं यंत्रतोरणेनाकृष्टकृपाणीव्यग्रपाणिरनास्था
धे दैव चंद्रगुप्ताशया वैरोचनकं हतस्तपस्वी बर्बरकः। ततो दारुवर्मणा यंत्रतोरणपातनमात्मविनाशफलकमवधार्य शी
घ्रमेव तुंगतोरणसमारूढेन यंत्रघटनबीजं लोहकीलकमादाय पट्टस्तिनीगत एव हतस्तपस्वी वैरोचनकः। राक्षः। हा कष्टम

१३ नर्थ हृदयमापतितं न हतश्चंद्रगुप्तो हतौ वैरोचकबर्बरकौ नं चैतौ हतौ दैवेन सर्वथा पर्यमेव कृताः। अथ सन्तेधारो दारुवर्मा किमु

विरोधैरोचनकपुरःसरेण पदातिलोकेन रकैके कलोष्टघातं कृतः। रा॰कृ। सात्वं कष्टमहो वक्कालेन स्तुत्य विमृष्टकाः समः अथ पश्चि नि

ज्ञातेनाऽभयदत्तेन किमनुष्ठितं। विरा। सर्वमनुष्ठितं। राक्षसः। अपि हतश्चंद्रगुप्तहतकः। विरा। अमात्य दैवान्न हतः। राक्षसः। सविस्मि

तं तत्किं विदारिणी कथयसि सर्वमनुष्ठितमिति। विरा। अमात्य कल्पितं मेतेन विषचूर्णमिश्रौषधं चंद्रगुप्ताय तच्च प्रत्यक्षीकुर्व

पपा ता चाणक्यहतकेन कनकभाजनेन वर्णांतरगमनमुपलभ्याभिहितं चन्द्रगुप्तः। वृषल सविषमिदमौषधं न पातव्यमिति। राक्षसः। श

ठः खल्वसौ वटुः अथ वैद्यः कथं। विरा। तद्वैद्यौषधं पायितस्तत्रोपरतश्च। राक्षसः। महान्कार्यराशिरुपरतः। अथ तस्य शयनाधिकृतस्य

आत्मविनाशः ५ प्रमोदकस्य किं वृत्तं। विरा। यदितरेषां। राक्षसः। सोद्वेगं कथमिव। विरा। स खलु मूर्खस्तं युष्माभिः प्रतिसृष्टं महांतमर्थराशिमवा

प्य महता व्ययेनोपभोक्तुमारब्धवान्। ततः कुतोऽयं धनागम इति पृष्टो यदा वाक्यभेदमाकुलमकरोत्तदा चाणक्यहतकेन विचित्रेण वधेन व्यापादितः। राक्षसः। सोद्वेगं कथमत्रापि दैवेनोपहता वयं। अथ शयानस्य चंद्रगुप्तस्य शरीरे प्रहर्तुमस्मा

भिः प्रयुक्तानां सुरंगामेत्य प्रथममेव निवसतां बीभत्सकादीनां कोवृत्तांतः। विरा। अमात्य कोवृत्तांतः। दारुणोर

कः। सावेगं। न खलु विदितास्तेन वसंतः। विरा। अथ किं। प्राकं चन्द्रगुप्तप्रवेशात् प्रविश्य माद्रेणैव शयनगृहं दुरात्मना अवलोकितं चाणक्य राम॰ १३

सास्त्रसरवे बिराधगुप्तपश्य दुरात्मनश्चंद्रगुप्तस्य दैवसंपदं सर्व एवोपरताः

हतकेन तत्रस्थस्या भित्तिच्छिद्राद्गृहीतभक्तावयवां निष्क्रामंतीं पिपीलिकामवलोक्य पुरुषगर्भमेतद्गृहमिति गृहीतार्थेन दाहितं तच्छ

शयनगृहं। तस्मिंश्च दह्यमाने धूमाभिहतदृष्टयः पूर्वमविहितमनुपगम्य द्वारं तत्रैव संतापाद्दुरात्मनः सर्व एवोपरताः। राक्षसः।

सास्रं। कष्टं भोः कष्टं कन्यायास्तस्य वधाय या विषमयी गूढं प्रयुक्ता मया दैवात्पर्वतकस्तया विनिहतो यस्तस्य राज्यार्द्धहृत्। ये शस्त्रेषु

रसेषु च प्रणिहितास्तैरेव ते घातिता मौर्यस्यैव फलंति पश्य विविधश्रेयांसि मन्नीतयः॥ १६॥ विरा। अमात्य तथापि प्रारब्धमपरित्याज्यमे

व। पश्य तत्तमात्य। प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमंति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्ध

मुत्तमगुणास्त्वमिवोद्वहंति॥ १७॥ किंच। किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्नि

श्चलः। किं त्वंगीकृतमुत्सृजन् कृपणवच्छ्लाघ्यो जनो लज्जते निर्व्यूढः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतं॥ १८॥ रा॰कृ। प्रारब्धमपरि

त्याज्यमिति प्रत्यक्षमेतद्भवतः। ततः शविरा। ततः प्रभृति चंद्रगुप्तशरीरे सहस्रगुणमप्रमत्तश्चाणक्यहतकः एभ्य ईदृशोऽभविष्यती

त्यन्विष्य निगृहीतवान्कुसुमपुरनिवासिनो युष्मदीयानाप्तपुरुषान्। रा॰कृ। सावेगं अथ के के निगृहीताः। विरा। आदौ तावत् क्षपण

कोजीवसिद्धिः सनिकारं नगरान्निर्वासितः। रा॰कृ। आत्मगतं एतत्तावन्न कंपनं न निष्परिग्रहं स्थानभ्रंशः पीडयिष्यति। प्रकाशं सखे

अथ कमपराधमुद्दिश्य निर्वासितः। विरा। एषराक्षसप्रयुक्तो विषकन्यया पर्वतेश्वरं घातितवानिति। रा॰कृ। आत्मगतं साधु कौटि

मलयं र

न१

१४ लसाधु परिहृतमयशः पातितमस्मासु वधातिनोद्विरञ्जहृदः। एकमपिनीतिवीजं बहुफलतामेतियस्यतवा॥१९॥ प्रकाशं ततः प्रविश
ति शूलं द्रुगुप्त शरीरमभिद्रोग्धुमनेन व्यापारिता दारुवर्मादय इति गेरे प्रख्याप्य शकटदासः शूलमारोपितः। राक्ष। सास्रं हा सख
शकटदास अयुक्तस्तवायमीदृशो मृत्युः अथवा स्वाम्यर्थमुपरतो न शोच्यस्त्वमसि वयमेवानुशोच्या ये नंदकुलविनाशेपि
जीवितुमिच्छामः। विरा। अमात्य नैतदेवं। स्वाम्यर्थ एव साधयितव्य इति। राक्ष। सखे चन्द्रसाभिरमुमेवार्थमालंब्य न जिजीविषोपर
लोकगतो देवः कृतघ्नैर्नानुगम्यते॥२०॥ विरा। अमात्य एवमेव। राक्ष। सखे कथ्यतामपरस्यापि सुहृदः सनस्य वृत्तांतः। विरा।
एतदुपलभ्य चंदनदासेनापवाहितं सोहोरौ नामात्यस्य कलत्रं। राक्ष। सखे क्रूरस्य चाणक्यवटोर्नार्पितमिति विरुद्धमनुष्ठितं
चंदनदासेन। विरा। नन्वयुक्ततरः खलु द्रोहः। राक्ष। ततः। विरा। ततो याच्यमानेनापि यदा न समर्पितममात्यकलत्रं ततः कुपितेन
चाणक्यवटुना। राक्ष। सा वेगं न खलु व्यापादितः। विरा। अमात्य न व्यापादितः किंतु गृहीतगृहसारः सपुत्रकलत्रो बंधनागारे
निक्षिप्तः। राक्ष। ततः किं परितुष्टः कथयसि अपवाहितं राक्षसकलत्रमिति। ननु वक्तव्यं संयतः सपुत्रकलत्रो राक्षस इति। ततः
प्रविश्य पटाक्षेपेण पुरुषः जेदु जेदु अमच्चो एसो खु सअडदासो पडिहारभूमीए उवट्ठिदो। राक्ष। अपि सत्यं। पुरु। अमच्च
पादोवजीविणो जणा ण अलिअं मंतिदुं जाणंति। राक्ष। सखे विराधगुप्त कथमेतत्। विरा। अमात्य स्यादेतदेवं यतोरक्षितव्यं भ राम. १४

वितव्यता। राक्ष। प्रियंवदक यद्येवं तर्हि किं विचारयसि क्षिप्रं प्रवेशय। पुरुषः। जं अमच्चो आणवेदि त्ति निष्क्रांतः। ततः प्रविश
ति सिद्धार्थकेनानुगम्यमानः शकटदासः। शक। स्वगतं। दृष्ट्वा मौर्यमिव प्रतिष्ठितपदं मूलं धरित्र्यां ततं लक्ष्मीमिव चेतनाप्रमथनी
मुन्मुच्य कंठस्रजं। श्रुत्वा स्वामुपरोधरौद्रविषमानाघाततूर्यस्वनान्न ध्वंसं प्रथममाभिघातकठिनं मन्ये मदीयं मनः॥२१॥ नाथेनाव
लोक्य सहर्षं। अये प्रत्ययममात्यराक्षसस्तिष्ठति। य एषः अक्षीणभक्तिः क्षीणेपि स्वाम्यर्थे धुरमुद्वहन्। पृथिव्यां स्वामिभक्तानां प्रमाणे
परमे स्थितः॥२२॥ उपसृत्य जयत्वमात्यः। राक्ष। नाथेनावलोक्य सहर्षं। सखे शकटदास दिष्ट्या दृष्टोसि। तत्परिष्वजस्व मामिति परि
ष्वज्य। इदमासनमास्यतां। शक। यदाज्ञापयत्यमात्यः इत्युपविष्टः। राक्ष। शकटदासको यमस्यत्वस्यानंदस्य हेतुः। शकटदास नेन प्रि
~~यदाज्ञापयत्यमात्य इत्युपविष्टः। राक्ष। शकटदासको यमस्यत्वस्यानंदस्य हेतुः।~~ शक। ... नेन प्रियसुहृदा सिद्धार्थकेन घातकान्वि नि५
द्राव्य वध्यस्थानादपहृतोस्मि। राक्ष। सहर्षं। भद्र सिद्धार्थक काममपर्याप्तमिदमस्य प्रियस्य तथापि गृह्यतामिति स्वगात्रादव
तार्य भूषणानि प्रयच्छति। सिद्धा। गृहीत्वा पादयोः पतति। अमच्च एसो मे पढमं पविट्ठस्स णत्थि को वि परिचिदो जत्थ एदं अम
च्चपसाअं णिक्खिविअ णिव्वुदो भविस्सं ता इच्छामि एदाए मुद्दाए मुद्दिदं अमच्चस्स ज्जेव्व भंडागारे णिक्खिविदुं जदा मे पउ
ओअणं तदा गेह्णिस्सं। राक्ष। भद्र को दोषः एवं क्रियतां। शक। यदाज्ञापयत्यमात्यः मुद्रां विलोक्य अमात्य नामांकितेयं

और

ग

मुद्रा·राक्ष॥ विलोक्यात्मगतं·सुतम मस्मद्दत्तं कं ताविनोदार्थिनगरान्निष्क्रामतोमम हस्तात्परिभ्रष्टा गृहीताकथं मम स्वहस्त मुपागता·भद्रा
१५ शु·भद्रसिद्धार्थककुतस्त्वयेयमधिगता॥ सिद्धा॥ अमात्य अस्ति कुसुमपुरे मणिकारश्रेष्ठी चंदनदासोनामतस्य द्वारभूमौ परिपतिता
मयं उपलब्धा॥ राक्ष॥ युज्यते॥ सिद्धा॥ अमात्य किं युज्यते॥ राक्ष॥ भद्र महाधनानां गृहद्वारे पतितस्यैवं विधस्योपलब्धिरिति॥ शक॥ सखे सि
द्धार्थक अमात्य नामांकितेयं मुद्रा·यदिदं तत्त्वेनार्थेन भवंतममात्यस्तोषयिष्यति तदिहमीयतां मुद्रा॥ सिद्धा॥ अमात्य ननु गौरवं सो भय
रितो सोऽहं इमाए मुद्दाए अमच्चो पसादं करेदि त्ति मुद्रां समर्पयति॥ राक्ष॥ शकटदास अनयैव मुद्रया स्वाधिकारे व्यवहर्तव्यं·शकट॥
यदाज्ञापयत्यमात्यः॥ सिद्धा॥ अमच्च विस्सवामि किंपि विअस्थि·राक्ष॥ ब्रूहि विश्रब्धं॥ सिद्धा॥ जाणादि जेव अमच्चो जह तं चाणक्क
वडुअं विप्पिअं करिअ कंक णत्थि पुणो पाडलिउत्ते पवेसो त्ति ता इच्छामि अहं अमच्चस्स जेव चलणे सुस्सूसिदुं॥ राक्ष॥ प्रियं नः किं
तु भद्र अभिप्रायापरिज्ञानादं नहितोऽस्माकमनुनयः तदेवं क्रियतां॥ सिद्धा॥ सहर्षं अणुग्गहिदो म्हि॥ राक्ष॥ शकटदास विश्राम्य परि
~~ताप्यादं नहितोस्माकमनुनयः तदेवं क्रियतां॥ सिद्धा॥ सहर्षमनुगृहीतोऽस्मि॥~~ शक॥ यदाज्ञापयत्यमात्य इति सिद्धार्थकेन सह निष्क्रांतः
॥ राक्ष॥ सखे विराधगुप्त वर्णय वृत्तांतं तदेवं अपि किं मे नोस्मदुपजापं चंद्रगुप्त प्रकृतयः॥ विरा॥ अमात्य बाढं मतेन तु प्रकाशं मम
१८ नुगमन्त एव·राक्ष॥ सखे किं तत्र प्रकाशं·विरा॥ अमात्य इदं तत्र प्रकाशं मलयकेतोरपक्रमणात् प्रभृति कुपितः चंद्रगुप्तश्चाणा॥ राम· १७

क्यस्योपरि चाणक्योऽपि जितकाशितया ततोऽसौ राजाज्ञाभंगेन चंद्रगुप्तस्य चेतः पीडामुपचिनोतीत्यनुभवमपि ममानुभवः॥ राक्ष॥ सहर्षं सखे विराध
गुप्त त्वमनेनाहितुंडिकच्छद्मना पुनः कुसुमपुरमेव व्रज तत्र हि मे सुहृत् स्तनकलशो नाम वैतालिकः प्रतिवसति स त्वया मद्वच
नात् वाच्यः चाणक्येन क्रियमाणेष्वाज्ञाभंगेषु चंद्रगुप्तः स त्वया समुत्तेजनसमर्थैः श्लोकैरुपश्लोकयितव्यः कार्यं च निभृतं करभकहस्तेन सं
देष्टव्यमिति॥ विरा॥ यदाज्ञापयत्यमात्य इति निष्क्रांतः॥ प्रविश्य पुरुषः·अज्ज एसो अमच्च सअडदासो विण्णवेदि एदे ति तिण्णि अलं
कारजोडा विक्किणिजन्ति ता पच्चक्खी करेदु अमच्चो त्ति॥ राक्ष॥ विलोक्यात्मगतं॥ अहो महार्हाण्याभरणानि·प्रकाशं॥ ब्रूहि शकटदासं· दा
परितोष्य विक्रेतारं गृह्यतामिति॥ पुरु॥ जं अमच्चो आणवेदि त्ति निष्क्रांतः॥ राक्ष॥ यावदहमपि कुसुमपुराय करभकं प्रेषयामि
उत्थाय अपि दुरात्मनश्चाणक्याच्चंद्रगुप्तो भिद्येत·अथवा॥ मौर्यस्तेजसि सर्वभूततलभुजामाज्ञापको वर्त्तते चाणक्योऽपि मदाश्रया
दयमभून्नृप इति जातस्मयः राज्यप्राप्तिकृतार्थमेकमपरं तीर्णप्रतिज्ञार्णवं सौहार्दात्कृतकृत्यतैव नियतं लब्धांतरं भेत्स्यति॥ एवं ४
इति निष्क्रांताः सर्वे इति द्वितीयोंकः॥ ततः प्रविशति कंचुकी·रूपादीन्विषयान्निरूप्य करणैर्येरात्मलाभस्त्वया लब्धस्तेष्वपि ते दूरार्ति
मुहताः स्वाम्यवबोधक्रियाः॥ अंगानि प्रसभं त्यजंति पटुतामाज्ञाविधेयानि मे न्यस्तं मूर्ध्नि पदं तवैव जरया तृष्णे मुधा ताम्यसि॥
परिक्रम्याकाशे भो भो सु[illegible]गांगप्रासादाधिकृताः पुरुषाः सुगृहीतनामधेयो देव चंद्रगुप्तः समाज्ञापयति·प्रवृत्तकौमुदीमहो

त्तवरमणीयं कुसुमपुरमवलोकयितुमिच्छामितात्क्रियंतामस्मद्दर्शनयोग्याः सुगांगप्रासादस्योपवनभूमयइति तत्किं चिरयंति
१९५ भवंतः। किं ब्रूथ आर्य किमिदं अविदितमेवार्येण देवस्य चंद्रगुप्तस्य कौमुदीमहोत्सवप्रतिषेधइति। आः देवोपहताः किमनेन अप्रा
णाहरेण वः कथोद्घातेन। शीघ्रमिदानीं आलिंगंतु गृहीतधूपसुरभिस्तंभान्पिनद्धस्रजः संपूर्णेंदुमयूखसंहतिरुचां स
च्छामराणां श्रियः। सिंहांकासनधारणाच्च सुचिरं संजातमूर्छामिव क्षिप्रं चंदनवारिणा सकुसुमः सेकोनुगृह्णातु गां॥२॥ मुत
किं कथयंति भवंतः एते त्वरामहे इति। भद्राः त्वरध्वं अयमागत एव देवश्चंद्रगुप्तः। य एषः। कुविश्रुद्धैः शैलैः पथि पथि विषमेष्वप्यच
लता चिरं धुर्येणोढा गुरुरपि भुवो यस्य गुरुणा। धुरं तामेवोच्चैर्नववयसि वोढुं व्यवसितो मनस्वी दम्यत्वात्स्खलति च दुःखं न सह
नेपथ्ये ते॥३॥ इत इतो देवः। ततः प्रविशति राजा प्रतीहारी च। राजा आत्मगतं। राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदप्रीतिस्थानं। कु
तः। परार्थानुष्ठाने रहयति नृपं स्वार्थपरता परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः। परार्थश्चेत्स्वार्थादभिमततरो हंत पर
वान्परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः॥४॥ अपि च दुराराध्या राजलक्ष्मीरात्मवद्भिरपि राजभिः। कुतः। तीक्ष्णादुद्विजते मृदौ
परिभवत्रासान्न संतिष्ठते मूर्खं द्वेष्टि न गच्छति प्रणयितामत्यंतविद्वत्स्वपि। शूरेभ्योप्यधिकं बिभेत्युपहसत्येकांतभीरूनहो श्री
र्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशं॥५॥ अन्यच्च। कृतककलहं कृत्वा स्वतंत्रेण तत्र किंचित्कालं व्यवहर्तव्यमित्यार्यादि रा.म. १६

ष्टाः। स च कथमपि मया पातकमिवाभ्युपगतः। अथवा सदार्योपदेशसंस्कृतमनसामस्माकं सर्वदैव स्वतंत्रा वयं। कुतः। इह विरचयन्सा
ध्वीं शिष्यः क्रियां न निवार्यते त्यजति तु यदा मार्गं मोहात्तदा गुरुरंकुशः। विनयरुचयस्तस्मात्संतः सदैव निरंकुशाः परतरमतः स्वातं
त्र्येभ्यो वयं हि पराङ्मुखाः॥६॥ प्रकाशं। आर्य वैहीनरे सुगांगप्रासादमार्गमादेशय। कंचुकी। इत इतो देवः। परिक्रम्य। अयं सुगांगप्रा
देवः सादः। शनैः शनैरारोहतु देवः। राजा नाट्येनावलोक्य। अहो शरत्समयसंभृतशोभाविभूतीनां दिशामतिशयरमणीयता। कुतः। शनैः
सलेक्षुमर्ध्वशांताकाराः सितजलधरच्छेदपुलिनाः पुरस्तात्कीर्णाः कलविरुतिभिः सारसकुलैः। चित्राश्चित्राकारैर्निशि विकचन
क्षत्रकुमुदैर्नभस्तः स्यंदंते सरित इव दीर्घा दशदिशः॥७॥ अपि च। आ पामुद्धत्तानां निजमुपदिशंत्या स्थितिपथं दधत्याशालीनाम
वनतिमुदारोस्तसफले। मयूराणां मुग्धं विषमिव हरंत्या मदमहो कृतः सर्वस्यायं विनय इव लोकस्य शरदा॥८॥ अपि च। इमानमपि
भर्तुस्तत्पाकलुषितां बहुवल्लभस्य कं बालकस्य विदवतीयितन्नभवंती। सर्वावनारामतिकथ्या चतुरेवहन्ती गंगा शरन्नयति सिंधुपतिं र
प्रसन्नां॥९॥ समंतादवलोक्य। अये कथमप्रवृत्तकौमुदीमहोत्सवं कुसुमपुरं आर्य वैहीनरे अथ अस्मद्वचनादघोषितो ।वि
तः कुसुमपुरे कौमुदीमहोत्सवः। कंचुकी देव अथ किं। आघोषितो देवस्याज्ञया कुसुमपुरे कौमुदीमहोत्सवः। राजा। आर्य त
त्किं न गृहीतमस्मद्वचनं पौरजनेन। कंचुकी। कर्णौ पिधाय। शांतं पापं अस्खलितपूर्वं देवस्य शासनं कथं पौरेषु स्खलिष्यतीति।

१२ वि राजा। आर्यवैहीनरे यद्येवं तत्किमप्रवृत्तकौमुदीमहोत्सवमद्यापि कुसुमपुरं पश्यामि। पश्य। धूर्तैरन्वीयमानाः स्फुटचतुरकथाको
विदैर्वेशनार्यो नालंकुर्वंति रथ्याः पृथुजघनभराक्रांतिमंदैः प्रयातैः। अन्योन्यं स्पर्द्धमाना न च गृहविभवैः स्वामिनो मुक्तशंकाः सा
कं स्त्रीभिर्भजंते विधिमभिलषितं पार्वणं पौरमुख्याः॥९॥ कंचु। देव एवमेव। राजा। किमेतत्। कंचुकी। अत इदं। राजा। आर्य स्फु
टमभिधीयतां। कंचु। देव प्रतिषिद्धः कौमुदीमहोत्सवः। राजा। सक्रोधं। आर्येण। कंचु। नातः परमस्माभिर्देवो विज्ञापयितुं श
क्यते। राजा। आर्य न खलु आर्यचाणक्येनापहृतः प्रेक्षकाणामतिशयरमणीयश्चक्षुषो विषयः। कंचु। देव जीवितुकामः कोन्यो
देवस्य शासनमुल्लंघयिष्यति। राजा। सक्रोधं। शोणोत्तरे उपवेष्टुमिच्छामि। प्रतीहारी। देव एदं सिंहासणं। उवविसदु देवो। रा
जा। नाट्येनोपविश्य। आर्य वैहीनरे आर्यचाणक्यं द्रष्टुमिच्छामि। कंचुकी। यद्देव आज्ञापयतीति निष्क्रांतः। ततः प्रविशति स्वभव
नगतः कृतासनपरिग्रहः कोपानुविद्धां चिंतां नाटयन् चाणक्यः। आत्मगतं। कथं स्पर्द्धते मया सह दुरात्मा राक्षसः। कुतः। कृ
तागाः कौटिल्यो भुजग इव निर्याय नगराद्यथा नंदं हत्वा नृपतिमकरोन्मौर्यवृषलं। तथाहं मौर्येंदोः श्रियमपहरामीति कृतधीः
प्रभावं मद्बुद्धेरतिशयितुमेष व्यवसितः॥१०॥ प्रत्यक्षवदाकाशे लक्ष्यं बध्वा। राक्षस२ विरम्यतामस्माद्दुर्व्यवसितात्। कुतः। उत्सि
क्तः कुसचिवदृष्टराज्यतंत्रो नंदोसौ न भवति चंद्रगुप्त एषः। चाणक्यस्त्वमपि च नैव केवलं ते साधर्म्यं मदनुकृतेः प्रधानवैरं॥११॥ विचिं राम. १२

वकारिणीं कृतधियः स्थानेश्ववृत्तिं विदुः॥१२॥ परिक्रम्यावलोक्य च। इदमार्यचाणक्यस्य गृहं यावत्प्रविशामि। नाट्ये ४

तन्नयवा। नातिमात्रमस्मिन्वस्तुनि मनः खेदयितव्यं। कुतः। मद्भृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रविष्टास्तैरेषु क्रमः स्वनियोग
साधनविधौ सिद्धार्थकाद्याः स्पशाः। कृत्वा संप्रति कैतवेन कलहं मौर्येण चाराश्च संभेत्स्यामि स्वमतेन भेदकुशलो ह्येष प्रतीपं द्विषः चे २
॥१३॥ प्रविश्य कंचुकी। कष्टा खलु सेवा नाम। कुतः। भेतव्यं नृपतेस्ततः सचिवाद्राज्ञस्ततो वल्लभादन्येभ्यश्च भवंति येस्य भवने
लब्धप्रसादा विटाः। दैन्यादुन्मुखदर्शिनोपलपनैः पिंडार्थमायस्यतः सेवां लाघवतः प्रविश्यावलोक्य च। अहो राजाधिराजस्य मं
ह् त्रिणो विभूतिः। कुतः। उपलशकलमेतद्भेदकं गोमयानां बटुभिरुपहृतानां बर्हिषां स्तूपमेतत्। शरणमपि समि
द्भिः शुष्यमाणाभिरुपहृतानां बर्हिषां स्तूपमेतत् शरणमपि समिद्भिः शुष्यमाणाभिराभि
र्विनमितपटलांतं दृश्यते जीर्णकुड्यं॥१४॥ तत्स्थाने स्य वृषलश्चंद्रगुप्तो देवः। कुतः। स्तुवंत्यश्रांतास्याः क्षितिपतिमभूतैरपि
गुणैः प्रवाचः कार्पण्याद्यदवितथवाचोपि पुरुषाः। प्रभावस्तृष्णायाः स खलु सकलः स्यादितरथा निरीहाणामीशस्तृणमि
मिव तिरस्कारविषयः॥१५॥ विलोक्य सभयं। अये अयमार्यचाणक्यस्तिष्ठति। य एषः। योनंदमौर्यनृपयोः परिभूय लोकमस्तोद
यावदिशाद्य विभिन्नकालं। पर्यायिकल्पितमहिमोऽसममसर्वगामि धामाभिशामयति धाम सहस्रधाम्नः॥१६॥ जानुभ्यां भूमौ निपत्य।
जयत्वार्यः। चाणक्यः। वैहीनरे किमागमनप्रयोजनं। कंचु। आर्य प्रणतिसंभ्रमचलितभूमिपालमौलिमणिशकल

१८ शिखापिशंगीकृतपादपद्मयुगलः पादयद्मयो राघस्य प्रणिपत्य देवश्चंद्रगुप्तो विज्ञापयति। अकृतकार्यांतरायमार्यं द्रष्टुमिच्छामी
ति। चाण॥ वैहीनरे न खलु वृषलस्य श्रवणपथमागतो मे कौमुदीमहोत्सवप्रतिषेधः। कंचु॥ आर्य अथ किं। चाण॥ स क्रोधं आः
केन कथितं। कंचु॥ सभयं नाट्येन प्रसीदत्वार्यः स्वयमेव सुगांगप्रासादगतेन देवेनावलोकितमप्रवर्त्यमानकौमुदीमहोत्सवं कु
सुमपुरं। चाण॥ ज्ञातं ततो भवद्भिरंतरे प्रोत्साह्य कोपितो वृषलः किमन्यत्। कंचु॥ सभयं अधोमुखस्तिष्ठति। चाण॥ अ
हो राजपरिजनस्य चाणक्यस्योपरि विद्वेषः। अथ क्व वृषलस्तिष्ठति। कंचु॥ सुगांगप्रासादगतेन देवेनाहमार्यस्य पादमूलं प्रे
षितः। चाण॥ उत्थाय। कंचुकिन् सुगांगप्रासादमार्गमादेशय। कंचु॥ इत इत आर्यः। उभौ परिक्रामतः। कंचु॥ आर्य अयं सुगांगप्रासा
दः सोपानमादेशय। कंचु॥ शनैरारोहत्वार्यः। चाण॥ नाट्येनारुह्यावलोक्य च सहर्षमात्मगतं अये सिंहासनमध्यास्ते वृ
षलः साधु २। नंदैर्वियुक्तमनपेक्षितराजराजैरध्यासितं च वृषलेन वृषेण राज्ञां सिंहासनं सदृशपार्थिवसंगतं च प्रीतिं परां प्र
गुणायंति गुणा ममैते।१७। उपसृत्य विजयतां वृषलेन वृषेण राज्ञां सिंहासनं सदृशपार्थिवसंगतं च प्रीतिं परां प्रगुणयं
ति गुणा ममैते। वृषलः। राजा॥ आसनादुत्थाय आर्य चंद्रगुप्तः प्रणमति। चाण॥ पाणौ गृहीत्वा उत्तिष्ठ वत्स। आशैलेंद्रा
च्छिलांतःस्खलितसुरनदीशीकरासारशीतात्तीरांतान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य। आगत्यागत्य भीतिप्रण राम॰ १८

भ्रां रा

तनृपशतैः शश्वदेव क्रियंतां चूडारत्नांशुगर्भास्तव चरणयुगस्यांगुलीरंध्रभागाः। राजा॥ आर्यप्रसादादनुभूयत एवैतत् आशास्ते
उपविशत्वार्यः। यथासनमुपविष्टौ। चाण॥ वृषल किमर्थं वयमाहूताः। राजा॥ आर्यस्य दर्शनेनात्मानमनुग्राहयितुं। चाण॥ स्मितं कृत्वा
उप वृषल अलमनेन प्रश्रयेण न निष्प्रयोजनमधिकारवंतः प्रभुभिराहूयंते तत्प्रयोजनमभिधीयतां। राजा॥ आर्य कौमुदीमहोत्स
वप्रतिषेधस्य किं फलमार्यः पश्यति। चाण॥ स्मितं कृत्वा वृषल तर्हि उपालब्धुं वयमाहूताः। राजा॥ नोपालब्धुं। चाण॥ किं तर्हि। रा
यद्येवं जा॥ विज्ञापयितुं। चाण॥ वृषल तर्हि विज्ञापनीयानां शिष्येणावश्यं रुचयो नानुरोद्धव्याः। राजा॥ कः संदेहः किंतु न कदाचिदार्यस्य नि
ष्प्रयोजना प्रवृत्तिरित्यस्ति नः प्रश्नस्यावकाशः। चाण॥ वृषल सम्यग्गृहीतवानसि न प्रयोजनमंतरेण चाणक्यः स्वप्नेऽपि चे
ष्टते। राजा॥ आर्य अत एव मां प्रयोजनं शुश्रूषा मुखरयति। चाण॥ वृषल इह खल्वर्थशास्त्रकारास्त्रिविधां सिद्धिमुपवर्ण
यंति। तद्यथा। राजायत्तां सचिवायत्तामुभयायत्तां चेति। ततः सचिवायत्तसिद्धेस्तव किं प्रयोजनान्वेषणेन यतो वयमेवात्र नियुक्ता वे
त्स्यामः। राजा सकोपमिव मुखं परिवर्तयति। ततो नेपथ्ये वैतालिकौ पठतः। आकाशं काशपुष्पच्छ ८३
विमभिभवता भस्मना शुक्लयंती शीतांशोरंशुजालैर्जलधरमलिनां क्लिश्नती कृत्तिमैभीं। कापालीमुद्वहंती स्रजमिव धव
लां कौमुदीमित्यपूर्वा हासश्रीराजहंसा हरतु तनुरिव क्लेशमैशी शरद्वः।१८। अपि च। प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्न

१९ दीपप्रभाणामात्मव्यापारेण गुर्वीजनितजललवार्द्रभरोः सांगच्छेत्। नागांकंमो कुमिच्छेषोः शयनमुरुफणाचक्रवालोपधानं निद्राछेदाभिताम्राविरमवतुहरेर्दृष्टिराकेकराणं वः॥ २९॥ द्वितीयः॥ सत्त्वोत्कर्षस्य धात्रा निधय इव कृताः केपि कस्यापि हेतोर्जेतारः स्वेनधाम्ना मदसलिलमुचां नागयूथेश्वराणां। दंष्ट्राभंगं मृगाणामधिपतय इव व्यक्तमानावलेपा नाज्ञाभंगं सहंते नृवरनृपतयस्त्वादृशाः सार्वभौमाः॥ ३०॥ अपि च। अभूषणोपभोगेन प्रभुर्भवति न प्रभुः। परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते॥ ३१॥ चाणक्यः। आकर्णितं यदि प्रथममंतावदिदमपि किं वद। अथवा विदितं। इदमपरं किमिति नोच्यते। यदि राजधारिष्यामीति चिंत्यं। आः भवतु ज्ञातं। राक्षसस्यापं प्रयोगः। दुरात्मन् राक्षस दर्पसे जागर्त्ति खलु कौटिल्यः। राजा। आर्य देवीही नेरतीय ताम्। भ्रकुंवे तालिकर्भ्यो सुवर्णशतसहस्रं। कंचुकी। यदाज्ञापयतिदेवः। इति परिक्रामति। चाणक्यः। सक्रोधं वैहीनेरयतामेतिष्ठ। नगंतव्यं। वृषल किमयमस्थाने महानर्थोत्सर्गः किंपते। राजा। आर्येणेवं सर्वत्र निरुद्धचेष्टाप्रसरस्य बंधनमिव राज्यं नेराज्यमिव। चाणक्यः। वृषल स्वयमनभियुक्तानां राज्ञामेते दोषा भवंति। तद्यदि न सहसे ततः स्वयमभियुज्यस्व। राजा। एते स्वकर्मण्यभियुज्यामहे। चाणक्यः। प्रियं नः स्वयमपि स्वकर्मण्यभियुज्यामहे। राजा। यद्येवं तेन हि आर्य। चाणक्य कौमुदीमहोत्सवप्रतिषेधस्य किं प्रयोजनमिति श्रोतुमिच्छामि। चाणक्यः। न हि कौमुदीमहोत्सवकरणप्रयोजनं श्रोतुमिच्छामि। राजा। प्रथमं तावन्ममाज्ञाव्या… राम॰ १९

विघातः। चाणक्यः। वृषल ममापि खलु प्रथमं त्वदाज्ञाविघातः एव कौमुदीमहोत्सवप्रतिषेधस्य प्रथमं प्रयोजनं। कुतः। अंभोधीनां तमालप्रभवकिसलयश्यामवेलावनानामापारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितांतर्जलानां। मालेवाम्लानपुष्पा नतनृपतिशतैरुह्यमाना शिरोभिः सा मय्येव स्खलंती कथयति विनयालंकृतं ते प्रभुत्वं॥ ३२॥ राजा। अथापरं प्रयोजनं श्रोतुमिच्छामि। चाणक्यः। तदपि कथयामि। राजा। कथ्यतां। चाणक्यः। शोणोत्तरे भद्रभटनात्कायस्थमचलं ब्रूहि। यत्तद्भद्रभटप्रभृतीनां लेख्यपत्रं तत्राव दीयतामिति। प्रतीहारी। जं अज्जो आणवेदित्ति निष्क्रम्य पुनः प्रविश्य अज्ज इमं पत्तं। चाणक्यः। वृषल श्रूयतां। राजा। दत्तावधानोस्मि। चाणक्यः। वाचयति। स्वस्ति सुगृहीतनामधेयस्य देवस्य चंद्रगुप्तस्य सहोत्थायिनां पुरुषाणामितोपक्रम्य मलयकेतुमाश्रितानां प्रमाणलेख्यं। तत्र प्रथममेव तावद्गजाध्यक्षो भद्रभटः। अश्वाध्यक्षः पुरुषदत्तः। महाप्रतीहारस्य चंद्रभानोः भागिनेयो डिंगिरातः स्वजनसंबंधी महाराजवल्लभो बलगुप्तः। देवस्य कुमारसेवको राजसेनः। सेनापतेः सिंहबलस्य कनीयान् भागुरायणः। मालवराजपुत्रो रोहिताक्षः। क्षत्रगणमुख्यो विजयवर्मेति। राजा। आर्य एतेषामपरागहेतुं श्रोतुमिच्छामि। चाणक्यः। वृषल श्रूयतां। अत्र यावेतौ गजाध्यक्षाश्वाध्यक्षौ भद्रभटपुरुषदत्तनामानौ तौ स्त्रीमद्यमृगयाशीलौ हस्त्यश्वावेक्षणानधिकारेण मया स्वाधिकाराभ्यामवरोप्य मयास्वजीवनमात्रेणावस्थापितौ। स्वेन सेनाधिकारेणाश्वस्थाप्य मलयकेतुमाश्रितौ। योचेतौ डिंगिराजवल

१० गुप्ताव यत्वं न लोभाभिभूतौ तद्दत्तं जीवनमबहुमन्यमानौ न अबकूलम्य न इति मलयकेतुमाश्रितौ॰ योग्य सोमवृत्तः कुमार
सेवको राजसेनः सोपि तव प्रसादात् त्रिमात्रकोपदत्तास्वैस ह सैव महदैश्वर्यमवाप्य पुनरुच्छेदाशंकयापक्रम्य मलयके
तुमाश्रितः॰ योयमपरः सेनापतेः सिंहबलस्य कनीयान्भ्राता भागुरायणः॰ असावपि तत्र काले पर्वतकेन सह समुत्पन्नसौ
हार्द्दः तत्प्रीत्या तदपि तातं चाणक्येन घातितइति रहसि त्रासयित्वा मलयकेतुमपवाहितवान्॰ ततो भवदपथ्यकारिषु चंदन
दासप्रभृतिषु निग्रहमारोपितेषु दोषाशंकयापक्रम्य मलयकेतुमाश्रितः॰ तेनाप्यसौ ममैतेन प्राणाः परिरक्षिता इति कृतज्ञ
तामनुवर्त्तमानेनैव केवलं च परिरक्ष्यमात्मनो नंतरं अमात्यपदं व्याहितः॰ यावेतौ रोहिताक्षविजयवर्म्माणौ तावप्यतेन माभिन्ता
त्स्वदायादेभ्यस्त्वयादीयमानं मानमसहमानौ मलयकेतुमाश्रितौ इत्येतेषामपरागहेतवः॥ राजा॥ आर्य एवमेतेषु परिज्ञाता
परागहेतुषु क्षिप्रमेव कस्मान्न प्रतिविहितमार्येण॰ चाण॥ वृषल न पारितं॰ राजा॥ किमकौशलादुत प्रयोजनापेक्षया॥ चाण॥
कथमकौशलं भविष्यति नियतं प्रयोजनापेक्षया॰ राजा॥ प्रयोजनमप्रतिविधानस्येदानीं श्रोतुमिच्छामि॥ चाण॥ वृषल
श्रूयतां॥ राजा॥ कथ्यतां॥ चाण॥ वृषल इह खलु विरक्तानां प्रकृतीनां द्विविधं प्रतिविधानं॰ तद्यथा अनुग्रहो निग्रहश्च
अनुग्रहस्तावदाक्षिप्ताधिकारयोर्भद्रभटपुरुषदत्तयोः पुनरधिकारारोपणमेव॰ स्वचत्ता हृयो पुव्यसनपो राम॰ १०

गादनमिपुक्तेषु पुनरारोप्यमाणाः सकलराज्यमूलं हस्त्यश्वमवसादयन्ति॥ डिंगिरातबलगुप्तयोरतिलुब्धप्रकृत्योः सकलराज्य
संपादनेनाप्यपरितुष्यतोरनुग्रहः कुतः कल्पते॥ राजसेनभागुरायणयोस्तु धनप्राणनाशभीतयोः कुतोनुग्रहस्या
वकाशः॰ रोहिताक्षविजयवर्म्मणोरपि दायादमानप्रदानपीडितयोः खल्वत्यंतमाभिमानिनोः कीदृशोनुग्रहः प्रीतिं जनयिष्यतीति
परिहृतः पूर्वः पक्षः॰ उत्तरोपि खल्वयमपि नतनैश्वर्यसहोत्थायिनं प्रधानपुरुषवर्गमुग्रेण दंडेन पीडयंतो नंदकुलानुरक्ता ऊध
नां प्रकृतीनामविश्वास्या एवमइयतः परिहृतः॰ एवं ततेदेवमस्मद्गृहीतास्मत्कुलपक्षो राक्षसोपदेशप्रवणो महीयान्म्लेच्छब
लेन परिवृतः पितृवधामर्षितः पर्वतकपुत्रो मलयकेतुरस्मानभियोक्तुमुद्यतः॰ सोयं व्यायामकालो न चोत्सवकाल इति
दुर्गसंस्कारे प्रारब्धव्ये किं कौमुदीमहोत्सवेनेति प्रतिषिद्धः॥ राजा॥ बहु प्रष्टव्यमत्र॥ चाण॥ वृषल विस्रब्धं पृच्छ॰ ममापि बहु
रव्येयमत्र॥ राजा॥ एष पृच्छामि॥ चाण॥ वृषल अहमप्येष कथयामि॥ राजा॥ आर्य सोप्यस्य सर्वस्यैवानर्थस्य हेतुर्मलयकेतुः
कस्मादपक्रामन्नुपेक्षितः॥ चाण॥ वृषल॰ अनुपेक्षितो द्वयीगतिः॰ स्यात्तन्निगृह्येत वा प्रतिश्रुतं राज्यार्द्धं वा प्रतिपाद्येत॰ निगृही
तावदस्य पर्वतकोस्माभिर्व्यापादितइति कृतघ्नतापाः स्वयं हस्तोदत्तः स्यात्॥ प्रतिश्रुतराज्यार्द्धप्रतिपादनेपि पर्वतकविनाशः
केवलमेव कृतघ्नतामात्रफलः स्यादिति मलयकेतुरपक्रामन्नुपेक्षितः॥ राजा॥ आर्य अत्र तावदेवं॰ राक्षसः पुनरिहैव वर्त्तमानो

११ गरे वर्त्तमान आर्येणोपेक्षितः तदत्र किमुत्तरमार्यस्य । चाण । वृषल राक्षसोपि खलु स्वामिनि स्थिरानुरागित्वात् सुचिरमेवात्र सं
वासाद्वा शीलज्ञानां नंदानुरक्तानां प्रकृतीनामत्यंतविश्वास्यः प्रज्ञापुरुषकाराभ्यामुपेतः सहायसंपदा युक्तः कोषवानिहैवा
न्तर्नगरे वर्त्तमानः खलु महांतमंतःकोपमुत्पादयेत् । दूरीकृतस्तु बाह्यकोपमुत्पादयन्नपि न दुःसाध्यो भविष्यतीत्यतोपक्रामन्
न नुपेक्षितः । राजा । तत्किमत्रस्थ एवोपायैर्नोपक्रांतः । चाण । कथमनुपक्रांतो नो भविष्यति । ननूपायैरेवासौ हृदयेशयः शंकुरिवो
द्धृत्य दूरीकृतः । दूरीकरणस्योक्तं प्रयोजनं । राजा । आर्य कस्माद्वा विक्रम्य न गृहीतः । चाण । वृषल । राक्षसः खल्वसौ विक्रम्य नि
गृह्यमाणः स्वयं वा विनश्येत् युष्मद्बलानि वा विनाशयेत् । एवं सत्युभयथापि दोषः पश्य । स हि भृशमुपयुक्तो यद्युपेयादपा
यं ननु वृषल वियुक्तस्तादृशेनासि पुंसा । अथ तव बलमुख्यान् घातयेत्सापि पीडा वनगज इव तस्मात्सोभ्युपायैर्विनेयः ॥ २२ ॥
राजा । न शक्नुमो वयमार्यस्य मतिमतिशयितुं सर्वथा अमात्यराक्षस एवात्र प्रशस्यतरः । चाण । स कोपं न भवानिति वाक्य
शेषः । भो वृषल तेन किं कृतं । राजा । श्रूयतां येन खलु महात्मना लब्धायां पुरि यावदिच्छमुषितं कृत्वाप
दं नो गले व्याघातो जयघोषणादिषु बलादस्मद्बलानां कृतः । अत्यर्थं विपुलेमनीतिविभवैः संमोहमापादिता विश्वा
स्येष्वपि विश्वसंति मतयो न स्वेषु वर्गेषु नः ॥ २३ ॥ चाण । वृषल एतत्कृतं राक्षसेन मया पुनर्ज्ञातं नंदमिव भवंतमुद्धृत्य भवानिव राम. २१

ने

मलयकेतू राजाधिराजपदे योजितः । राजा । अन्येनैवेदमनुष्ठितं किमत्रार्यस्य । चाण । अयि हे मत्सरिन् आरुह्यारूढकोपस्फुरदरुणवि
षमिताग्रांगुलीमुक्तचूडां लोकप्रत्यक्षमुग्रां सकलरिपुकुलोत्सादिदीर्घां प्रतिज्ञां । केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटी
श्वरास्ते नंदाः पर्यायभूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २४ ॥ अपि च । गृध्रैराबद्धचक्रं वियति विचलनयादीर्घनिःकंपपक्षैर्धू
मैर्ध्वस्तार्कभासां सघनमिव दिशां मंडलं दर्शयंतः । नंदानानंदयंतः पितृवननिलयान्प्राणिनः पश्यतैतान् निर्वांत्यद्यापि नैते स्रु
तबहलवसावाहिनो हव्यवाहाः ॥ २५ ॥ राजा । अन्येनैवेदमनुष्ठितं । चाण । केन । राजा । नंदकुलद्वेषिणा दैवेन । चाण । दैवमविद्वांसः प्र
माणयंति । राजा । विद्वांसोप्यविकत्थना भवंति । चाण । सकोपं । वृषल भृत्यमिव मामारोढुमिच्छसि । शिखां मोक्तुं बद्धामपि पुनरयं
धावति करः । भूमौ पादप्रहारं दत्वा । प्रतिज्ञामारोढुं पुनरपि चलत्येष चरणः । प्रणाशान्नंदानां प्रशममुपयातं त्वमधुना परीतः का
लेन ज्वलयसि पुनः क्रोधदहनं ॥ २६ ॥ राजा । सावेगमात्मगतं । अये कथं सत्यमेवार्यः कुपितः । तथाहि । संरंभोत्स्पंदिपक्ष्मक्षर जो
३न्वे दमलजललक्षालनक्षामयापि भ्रूभंगोद्भेदधूमं ज्वलितमिव पुरः पिंगया नेत्रभासा । मन्ये रुद्रस्य रौद्रं रसमभिनयतस्तांडवेषु स्म
रंत्या संजातोग्रप्रकंपं कथमपि धरया धारितः पादघातः ॥ २७ ॥ चाण । कृतककोपं संहृत्य । वृषल अलमुत्तरोत्तरेण यदि मत्तो गरी
यान् राक्षसोवगम्यते तस्मादिदं शस्त्रं तस्मै दीयतां । इति शस्त्रमुत्सृज्योत्थाय च प्रत्यक्षरूपदाकाशे लक्ष्यं बद्ध्वा स्वगतं । राक्षस एष म

२

भ ए:

व नः कौटिल्यबुद्धिविजिगीषोर्बुद्धेः प्रकर्षः। चाणक्यमतमलिनेनाकिमहं स्तुदेवेन जेष्यामि मोर्यम् इति संप्रतियः प्रयुक्तः। भैः किलेष भ
२२ क्ताः सकलः सर्वसंपत्सु तेन नन्दवंशहस्तगाया २४ इति निष्क्रांताः प्रवेशकः। राजा आर्य दैवहीने रे अघ मल्लस्तना हस्तचाणक्यं
चंद्रगुप्तः स्वयमेव राज्यं करिष्यतीति गृहीतार्थाः किं येनोपकृतं तेषः। कंचुकी आत्मगतं। कथं निरूपपदमेव चाणक्य इत्यानार्य चाणा
४ र्थ क्य इति हंतो अधिकारः। अथवा न खलु उपस्तुनि देवंदोषेणाधिगंतुमर्हामि। कुतः सदोषः सचिव स्वैकमदसत्कृतेनैव नृपः। प्रमाति
यं तुः प्रमादेन गजो व्यालत्वमाच्युते। २९। राजा आर्य किं विचारयसि। कंचुकी देव न किंचिद्धि चार्यते दिष्ट्या देव इदानीं देवः संवृत्तः। राजा
आत्मगतं एवमस्मासु निगृह्यमाणेषु स्वकार्यसिद्धिकामः सकामो भवत्वार्यः। प्रकाशं आर्य शोणोत्तरे अनेन शुष्ककलहेन
शिरोवेदनामां बाधते। शयनगृहमादेशय। प्रतीहारी एतु एतु देवः। राजा आसनादुत्थाय स्वगतं। आर्याज्ञयैवममलंघितगौरवस्य
बुद्धिः प्रवेष्टुमिव भूविवरं प्रवृत्ता। ये सत्यमेव न गुरून् प्रतिमानयंति तेषां कथं नु हृदयं न भिनत्ति लज्जा। ३१ इति निष्क्रांताः सर्वे तृ
तीयोंकः। ततः प्रविशत्यहिगृहे वेषः पुरुषः। २ हीश्माराहेज्जो अराअंसमहिअंकोराममंगअंगअंइहेकोरेज्जा। अद्धा रागमराण
द्दीपक्करोअसमजइराहोज्जा। ३। आवेअमहवरकरवसस्स पससोक करभओकरभ ओविअनुअरंतोपाडलिउभोदाआअदे त्ति।
प्रविश्य दौवारिकः। भद्र मा उद्दंमं ते हि रमोअमहवरकरवसोकजा वि ताउ सिरिरां जागरएरां समुप्पादिदसीसवेदरो अजविरा स.म. २३

गेहंगच्छामि। परिश्रांतवसरिक्कम्पभो कोरच्छ दोवारि आणंतिवेदेहन्नदिशो अमघर खवसस्स २

१ वसरो अविय सुहोगम णं तिवेदे किमि पुढ़। भद्द मुह तहा करेमि। ततः प्रविशति शयनतलगतः आसनस्थेन

हर

दावसअराअलंविमुंचदितांविहदुसुहत्रसंजावलक्षाशकदासेन सहस्यितोराक्षसः। आत्मगतं मम हि प्रसन्नतः कार्यारंभे वि
२ धेरवि धेयतामपि च कुटिलां कौटिल्यस्य प्रचिंतयतो मतिं। अथ च विहिते मत्कृत्या नो निकाममुपग्रहे कथमिदमिति द्वैधीभूतं प्रयोतानि
शं निपद्यः।३। अपि चा कार्येपि हेपमादेन तु मविरचयंतस्य विस्तारमिच्छ चवीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च। कुर्व
न्बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा। ४। तदपि नाम दुरात्मा उ
चाणक्यवटुः। उपसृत्य दौवारिकः अनुदु श राक्षसः। अभिसंधातुं शक्यः स्यात्। दौवा। अमच्चो। राक्षसः। शामात्यि संदनं सूचयित्वा। आत्म
गतं दुरात्मा चाणक्यवटुर्जय तु अभिसंधातुं शक्यो मात्य इति वागेश्वरी वामाक्षि संदने न प्रस्तावगता प्रतिपादयति। तथापि नो
घ द्यमस्त्याज्यः। प्रकाशं भद्र किमसि वक्तुकामः। दौवारिकः। अमच्च एसो करभओ दुवारे चिट्ठदि। राक्षसः। आर्य किं विचारयसि शीघ्रं
प्रवेशय। पुरुषः। जं अमच्चो आणावेदि त्ति पुरुषमभिसृत्य एसो अमच्चो चिट्ठदि उवसप्पेहि णं इति निष्क्रांतो दौवारिकः। करभकः। ह४
उपसृत्य जअदु २ अमच्चो। राक्षसः। नाथेनावलोक्य भद्रकरभक स्वागतं उपविश्य तां करभः। जं अमच्चो आणावेदि त्ति भूमावुपविष्टः।
राक्षसः। आत्मगतं कस्मिन् प्रयोजने मयायं प्रहित इति प्रयोजनानां बहुत्वान्न खलु गच्छामि इति चिंतां नाटयति। ततः प्रविशति वे
त्रपाणिर्द्वितीयः पुरुषः। अहो सलहमअ जामाअसलहवेहमाराबाअवहंता किरांपकठपं द्रलेपचारुनी दंसरां मपिदुल्लहं अ सेः

अ१

२३ हि।कलशाकुलहरणादेवाशावभ्रमिदेवारंगौ॥ आकाशे। अन्यत्किंभणसि आह किंशि। मिद्धं श्रीसालशाकलीयंत्रिमन्नोरसेकरतुकुमा
लोमलयकेतुःसमुपस्पर्शीसैवेअशांअमछेलकृतुसंपेकिरठुंइदरोजेहंश्रोश्रवदित्तारदिशाकालशेशाश्रोसालशाकरीअ
दित्तिनिष्क्रांतः।पुरुषः॥ततःप्रविशतिभागुरायणेनकंचुकिनाचानुगम्यमानोमलयकेतुः॥निश्वस्यात्मगतं॥अद्यदशमोमास
स्तातस्योपरतस्य नचास्माभिर्वृथापुरुषाभिमानमुद्वहद्भिस्तमुद्दिश्यतोयांजलिरप्यावर्जितःप्रतिज्ञातंचमेतत्पुरस्ता
द्वक्षस्ताडनभिन्नरत्नवलयंभ्रष्टोत्तरीयांशुकंहाहेतुस्वरितार्त्तनादकरुणंभ्र त्र
रेणुरूषालकं।तादृशमातृजनस्यशोकजनितंसंप्रत्यवस्थांतरंशत्रुस्त्रीषुमयाविधायगुरवेदेयोनिवापांजलिः॥५॥ किमत्रबहुना
उद्यच्छताधुरमकापुरुषानुरूपांगंतव्यमाजिनिहतेनपितुःपथावा।आक्षिप्यमातृजननीजनलोचनेभ्योनेयोमयारिपुवधूनयना
निवापः॥६॥प्रकाशं।आर्यजाजले।उच्यंतामस्मद्वचनादनुयायिनोराजानः।एकएवाहममात्यराक्षसस्यातर्कितगमनेनप्रीतिमु
त्पादयितुमिच्छामि।अलमतःकृतममानुगमनक्लेशेनेति।कंचुकी।यदाज्ञापयतिकुमारः।परिक्रम्याकाशे।भोभोराजानःकुमारःसमाज्ञाप
यति।नखल्वहंकेनचिदनुगंतव्यः।विलोक्यसहर्षं।कुमारस्याज्ञानंतरमेवप्रतिनिवृत्ताःसर्वेराजानः।पश्यतुहिकुमारः।सोत्सेधैःस्कं
धदेशैःखरकविकक्शाकर्षणात्पर्यभुग्नैरश्वाःकेचित्प्रिरुद्धाःस्तिमितवरखुरध्येदैःखंडयंतःपुरस्तात्।केचिन्मातंगमुख्यैर्विगतजवता रा.म.
२३

जरी

मामूकघंटैर्विवृत्तामर्यादांभूमिपालाजलधयइववेलांदेवनोल्लंघयंति॥७॥मलय।आर्यत्वमपिसपरिजनोविनिवर्त्तस्व।भागु
रायणएकोमामनुगच्छतु।कंचुकी।यदाज्ञापयतिकुमारइतिनिष्क्रांतः।मलय।सखेभागुरायणविज्ञप्तोहमिहागच्छद्भिर्भद्रभटप्रभ
भृतिभिर्यथानवयममात्यराक्षसद्वारेणकुमारमाश्रयणीयमाश्रयामहे।किंतुकुमारस्यसेनापतिंशिखरसेनमद्रीकृत्यदुष्टामा
त्यपरिगृहीताच्चंद्रगुप्तादपरक्ताःकुमारमाभिरामिकगुणयोगादाश्रयणीयमाश्रयामह इतितन्मयासुचिरमपिविचारयता
तेषामयंवाक्यार्थोवधारितः।भागु।कुमारनदुर्बोधोयमर्थो।विजिगीषुरात्मगुणसंपन्नंप्रियहितद्वारेणाश्रयणीयमाश्रयेदिति
ननुत्वांन्यायं।मल।सखेभागुरायणनन्वस्माकममात्यराक्षसःप्रियतमोहिततमश्च।भागु।एवमेतत्।किंत्वमात्यराक्षसश्चा
णाक्यवद्धवैरोनचंद्रगुप्ते।तद्यदिकदाचिद्विचंद्रगुप्तम्राणाक्यमतिजितकार्येनमसहमानःसाचिव्यादवरोपयेत्।ततोनंदकुल
श्मा भक्तिमानंदान्वयएवायमितिसपक्षसुहृज्जनापेक्षयाचास्मात्यराक्षसश्चंद्रगुप्तेनसहसंदधीत।चंद्रगुप्तोपिपितृपर्यायागत
उमनु एवायमितिसंधिमनुमन्येत।एवंसत्यस्मासुकुमारोनविश्वसेदितिस्यादेषांवाक्यार्थः।मलयकेतुःयुज्यते।अमात्यगृहंप्रविशतुकुमारः।म
लयकेतुःएषप्रविशामि।ततःप्रविशत्यासनस्थःप्रकाशोपविष्टःकुसुमपुरेस्तयासनकस्मात्यराक्षसस्यगृहमादेशय।भागु
इतःइतःकुमारः।उभौपरिक्रामतः।भागु।कुमारात्यराक्षसस्यअलपाःपुरा।अमञ्च।अयंइ।मल।आकर्ण्यभागुरायणकुसुमपुरवृ ॥

रेङ्दमरे

१४ त्तोतः प्रस्तूयते तत्रभावदुयसषर्मिः म्हराउमस्त्ता वर्त्तिं कारणमिति । स स्वभंगभयाद्धा नो कथयंतं स्य यथा पुरः अन्यथा दिव्यतोर्यभुसे
रालोपखुमं त्रिरागः ॥१॥ भागु । यदाज्ञापयति कुमारः । राक्ष । भद्र अपि तत्कार्यसिद्धं । पुरु । अमच्च पसाएण सिद्धं । मल । भागुरायण । किं
तत्कार्यं । भागु । कुमार गहनः सचिववृत्तांतो नेनावतापरिच्छेत्तुं शक्यते अवहितस्तावच्छ्रोतुमर्हति कुमारः । राक्ष । भद्र विस्तरेण
श्रोतुमिच्छामि । पुरु । सुणादु अमच्चो अत्थि दाव अहं अमच्चेण आणत्तो जहा करभअ कुसुमउरं गदुअ महव अण्णे राभणिदव्वो वे
आलिओ थणअलसो जहा चाणक्कहदएण तेसु अण्णाणभंगेसु अणुचिट्ठिअमाणेसु चंदउत्तो उत्तेअणसमत्थेहिं सिलोअइद
वोत्ति । राक्ष । भद्र ततस्ततः । पुरु । तदो मए पाडलिउत्तं गच्छिअ अत्तणो विओअसस्स संदेसं वेआलिओ थणअलसो उत्थंतरे णा
दउलविणासदुम्मिअस्स पोरजणस्स परितोसं समुप्पादअंतेण चंदउत्तेण आघोसिओ । सो अ चिरकालपरिवद्धमाणउत्तरिगद्द
परिच्छओ अहिमदवंधु ~~[illegible]~~ अणसम्माणमो विअससिरोह मारिदोराअणे अरजेएण । राक्ष । सबाष्पं । हा देव नंद कौ
पर मुदी कुमुदानंदे जगदानंद हेतुना । कीदृशी सति चंद्रेऽपि नृपचंद्र त्वया विना ॥५॥ पुरु । तदो सो लोअस्स णअणाणंदभूदो वि अणिच्छंतस्स
ज्जेव राअरजणस्स तिव्वारिदो चाणक्कहदएण । एत्थंतरे थणअलसेण पउत्तो समुत्तेजणसमत्था सिलोअपडिवाडी । रा
क्ष । सहर्षं । साधु सखे स्तनकलश साधु । काले भेदवीजमुत्तमवश्यं फलमुपदर्शयति । कुतः । सद्यः क्रीडारसच्छेदं प्राकृतोऽपि न राम. २४

कोमुदीमहूसवउ५

मर्षयेत् । किं नु लोकाधिकं तेजो बिभ्राणः पृथिवीपतिः ॥६॥ मल । एवमेतत् । सघटप्रपदि पुनः पठति । राक्ष । भद्र ततस्ततः । पुरु । तदो चंदउत्तेण
आणाभंगकलुसिदेण सुइरं अमच्चस्स गुणं पसंसिय पदभंसिओ अहिआरादो चाणक्कहदओ । मल । सखे गुणप्रशंसया दर्शित
मस्मिंद्रगुप्तेन राक्षसे पक्षपातः । भागु । न तथा गुणप्रशंसया यथा चाणक्यवटोर्निराकरणेन । राक्ष । किमयमेव कौमुदीमहोत्सवप्रति
षेधश्चंद्रगुप्तस्य चाणक्यं प्रतिकोपकारणं । उतान्यदप्यस्ति । मल । सखे भागुरायण चंद्रगुप्तस्यापरकोपकारणान्वेषणेन किं फल
मेष पश्यति । भागु । कुमार मतिमांश्चाणक्यो न निष्प्रयोजनं चंद्रगुप्तं कोपयिष्यति । न च कृतवेदी चंद्रगुप्त एतावता गौरवमुल्लंघयि
ष्यति । सर्वथा चाणक्यचंद्रगुप्तयोः पुष्कलात्कारणाद्यो विश्लेष उत्पद्यते स आत्यंतिको भवतीति । पुरु । अमच्च अत्थि अण्णाइं वि
चंदउत्तस्स कोवकारणाइं । राक्ष । किं किं । पुरु । उवेक्खिदो णेण अवक्कमंतो मलयकेदू अमच्चरक्खसो अत्ति । राक्ष । सहर्षं शकटदास
हस्ततलगतो मे चंद्रगुप्तो भविष्यति । इदानीं चंदनदासस्य बंधनान्मोक्षस्तव च पुत्रदारैः सह समागमः । मल । सखे भागुरायण ह
स्ततलगतो मे चंद्रगुप्त इति व्याहरतः कोऽस्याभिप्रायः । भागु । किमन्यच्चाणक्यादपकृष्टस्य चंद्रगुप्तस्योद्धरणान्न किंचित्कार्यम
वश्यं पश्यति । राक्ष । भद्र हृताधिकारः क्वासांप्रतमसौ बटुः । पुरु । ताहिं जेव्व पाडलिउत्ते अहिवसदि । राक्ष । ~~[illegible]~~
~~[illegible]~~ सोद्वेगं । तत्रैव प्रतिवसति न तपोवनं गतः प्रतिज्ञां वा पुनर्न समारूढवान् । पुरु । अमच्च तवोवणं

गच्छद्भिस्तूर्णी आदि।राक्षः।प्रकटदास भेदमुपपद्यते।पश्य।देवस्य येन पृथिवीतलवासवस्य सा आसनापनयनानिकृतिर्न सोढा।
सोयं स्वयं कृतनराधिपतेर्मनस्वी मौर्यात्कथं नु परिभूतिमिमां सहेत॥९॥मल।सखे भागुरायण साचाणक्यवनगमने पुनः प्रतिज्ञारो
हणाय का अस्य स्वार्थसिद्धिः।भागु।नात्यंतदुर्बोधोयमर्थः।यावच्चाणक्यहतकमस्माद्दूरीभवति तावदनायासेनास्य स्वार्थसि
द्धिः।शकट।अलमन्यथाविकल्पेनोपपद्यत एवैतत्।पश्यत्वमात्यः।राज्ञश्चूडामणौ द्युतिखचितशिरः स्वमूर्ध्नि विन्यस्तपादः
स्वैरेवोत्पाद्य मानं किमिति विषहते मौर्य आज्ञादिघातं।कौटिल्यः कोपनोपि स्वयमभिचरणज्ञातदुःखप्रतिज्ञो दैवात्तीर्णप्रतिज्ञः
पुनरपि न करोत्यायतिग्लानिभीतः॥११॥राक्ष।शकटदास एवमेतत्।गच्छ विश्रामय करभकं।शकट।यदाज्ञापयत्यमात्य इति पुरुषेण सह निष्क्रान्तः।राक्ष।अहमपि कुमारं द्रष्टुमिच्छामि।मलय।अहमेवार्यं द्रष्टुमुपागतः।राक्ष।नाट्येनावलोक्य अये कुमारः।आसना
दुत्थाय अयमासनमुपवेष्टुमर्हति कुमारः।मल।अयमुपविशामि उपविशत्वार्य इति यथासनमुपविष्टौ।मल।आर्य अपि सह्या ध्या ४
शिरोवेदना।राक्ष।कुमार।कुमारस्याधिराजशब्देनातिरस्कृते कुमारशब्दे कुतो मे शिरोवेदनायाः सह्यता।मल।उरीकृतमेतद्दुर्ल
भं न दुःप्राप्यं भविष्यति।तत्कियन्तं कालमाशः प्रतिष्ठस्व विजयाय।मल।आर्य शत्रोर्व्यसनमुपलब्धं।राक्ष।उपलब्धं।मल।कीदृशं।राक्ष।स
चिवव्यसनं किमन्यदपकृष्टश्चाणक्याच्चन्द्रगुप्तः।मल।आर्य सचिवव्यसनमव्यसनमेव।राक्ष।अन्येषां भूमिपतीनां कदाचिदेव राम. २५
कालमस्माभिरेवं सन्नद्धैः परिशत्रुव्यसनमुदीक्षमाणैरुदासितव्यं।राक्ष।कुमार कुतोद्यापि कालहरणस्यावर

मपि स्यात्तन्न पुनश्चन्द्रगुप्तस्य।मल।नैतदेवं।किं कारणमिति।चन्द्रगुप्तप्रकृतीनां चाणक्यदोषा एवापरागहेतवः।तस्मिंश्च निराकृते प्र
थमम पि चन्द्रगुप्तमनुरक्ताः संप्रति सुतरामेव तत्रानुरागं दर्शयिष्यन्ति।राक्ष।कुमार नैतदेवं।ताः खलु द्विप्रकाराः प्रकृतयः चन्द्रगु
प्तसहोत्थायिन्यो नन्दकुलानुरक्ताश्च।तत्र चन्द्रगुप्तसहोत्थायिनीनां चाणक्यदोषा एव विरागहेतवो न नन्दकुलानुरागिणीनां।तास्तु खलु
नन्दकुलमनेन पितृभूतं कृतघ्नेन घातितमित्यपरागामर्षाभ्यां विप्रकृताः सत्यः स्वाश्रयमलभमानाश्चन्द्रगुप्तमनुवर्तन्ते।त्वादृशं पुनः
प्रतिपक्षोद्धरणे संभाव्यशक्तिमभियोक्तारमासाद्य क्षिप्रमेनं परित्यज्य त्वामुपयास्यन्तीति।अत्र निदर्शनं वयमेव।मल।आर्य किमेतदेकं स
चिवव्यसनमभियोगकारणं चन्द्रगुप्तस्याहोस्विदन्यदप्यस्ति।राक्ष।कुमार किमन्यैर्बहुभिरपि एतद्धि प्रधानतमं।मल।आर्य कथं प्र
धानतममेतत्।किमिदानीं चन्द्रगुप्तः स्वकार्यधुरमन्यत्र मंत्रिण्यात्मनि वा समासज्य स्वयं प्रतिविधातुमसमर्थः।राक्ष।बाढमसम
र्थः।किं कारणमिति।स्वायत्तसिद्धिषु उभयायत्तसिद्धिषु वा भूपालेषु तत्संभवति।चन्द्रगुप्तस्तु दुरात्मा नित्यं सचिवायत्तसिद्धाववस्थित
श्चक्षुर्विकल इवाप्रत्यक्षलोकव्यवहारः कथं स्वयं प्रतिविधातुं समर्थः स्यात्।किंच।नृपे पापकोपः सचिवात्र दर्पिताः स्तनंधयो त्यंत
शिशुस्तनादिव।स्वस्त्रलोकव्यवहारमंदधीर्मुहूर्त्तमप्युत्सहते न तेन वर्त्तितुं॥१२॥लेमेस्त्रात्मगतं।दिष्ट्या न सचिवायत्ततंत्रोस्मि।प्रकाशं।
यद्यप्येवं तथापि खलु बद्धमूलस्याभियोक्तारो व्यसनेषु सत्सु व्यसनिनं शत्रुमभियुञ्जानस्याभियोक्तुरैकान्तिकी कार्यसिद्धिर्भवति।राक्ष।

२६ ऐकांतिकीमेवसिद्धिमवगंतुमर्हतिकुमारः।कुतः।लप्पुत्तक्त्तबलेमियोक्तरिन्द्वपेनंदानुरक्तेपुरेचाणक्येचलिताधिकारविमुखेमें
र्यनवेराजनि।स्वाधीनेमयि।इतपदैकेलज्जानाटयत्र।मार्गमोत्रकृपनव्यापारमात्रोषमेत्त्वहो।छांतरितानिसंप्रतिविभातिसं
तिसाध्यानिनः॥१३॥मलाय्यचैवमभियोगकालमार्गंप्रपश्यतितत:किमास्यते।उत्तुंगास्तुंगकूलंस्नुतमदसलिलाःप्रस्यंदिसलि
लंश्यामाःश्यामोपकंठद्रुममलिमुखराःकल्लोलमुखरं।स्रोतःखातावसीदत्तटमुरुदशनैरुत्सादितनत्व्याःशोणांसिंदूरेशो
णाममगजपत्तपःपास्यंतिशतशः॥१४॥अपिच।गंभीरगर्जितरवाःस्वमदांबुमिश्रमासारवर्षमिवशीकरमुद्गिरंत्यः।विंध्यादि
कीर्णसलिलाइवमेघमालारुंधंतुवारणघटानगरंमदीयाः॥१५॥इतिसहभागुरायणेननिष्क्रांतः।राक्ष।कःकोत्रभोःप्रविश्यपुरु
षः।आणवेदुअमच्चो।राक्ष।प्रियंवदकसांवत्सरिकाणांद्वारिकस्तिष्ठति।पुरुषः।निष्क्रम्यपुनःप्रविश्यखवणओ।राक्ष।आत्मम
तंअनिमित्तंसूचयितावकथंप्रथममेवक्षपणकः।पुरु।जीवसिद्धी।राक्ष।भदंतनिरूप्यतांतावदस्मत्प्रस्थानदिवसः।क्षप।नाथ चंदगुत्तः
नचिंतयित्वा।उवासगाणिरुविदाआमज्जणादोणिवत्तंसत्तमकल्लाणा।सोहणातिथीसंपुस्सणसीतुह्माणं।उत्तलादिसाएदक्खि
णादिसं।पत्थिदाणंदक्खिणाडुवालिएणक्खत्ते।अविअ।अत्थाहिमुहेसूलेउइदेसंपुस्सम्मंडलेचंदे।गमणोबुद्धस्सलग्गोउदिआ
त्थमिदेअकेदुम्मि॥१६॥राक्ष।भदंततिथिरेवनशुद्ध्यति।क्षप।सावगाएक्कगुणातिहीचउग्गुणोणक्खत्तंचउसट्ठिगुणोलग्गोएसोजो राम. २६
४ वस्सअबीभसद्दर्शनंकृत्वाप्रवेशय।पुरु।जंअमच्चोआणवेदित्तिनिष्क्रांतः।ततःप्रविशतिक्षपणकः।सासणमरिहं
४ ताणंपडिवज्जहमोहवाहिविज्जाणं।जेविमुहमेत्तकडुअंपच्छापच्छंउवदिसंति॥१७॥उपसृत्य।धम्मविद्धीहोदुसावगाणं।राक्ष।४

इसत्तंतंसिद्धंतें।तालग्गोहोइसुलग्गोसोममम्मिगहम्मिहोइदुल्लग्गो।पाविहसिद्धिंहसिद्धींचंदस्सबलेणगच्छंतो॥१८॥राक्ष।भदंतअप
रैःसांवत्सरिकैःसहसंवाद्यतां।क्षप।संवादेदुसावगोअहंउणागमिस्सं।राक्ष।नखलुकुपितोभदंतः।क्षप।कुविदेणातुह्माणंभदंतो
राक्ष।कस्तर्हि।क्षप।भयवंकयंतोजेणअप्पणोपक्खंउज्झिअपरपक्खंपमाणीकरेसित्तिनिष्क्रांतः।राक्ष।प्रियंवदकज्ञाय
तांकावेलावर्ततइति।पुरु।अमच्चअत्थाहिलासीभअवंसूरो।राक्ष।आसनादुत्थायविलोक्यअयेमत्पस्वामिनीभगवतांभास्क
रः ~~संक्रासिहि।पुरु।अमच्चअत्थाहिलासीभअवंसूरो।राक्ष।आसनादुत्थायविलोक्यअयेमत्प~~ संप्रतिहि।आविर्भूतानुरागाः
क्षणमुदयगिरेरुज्जिहानस्यभानोःपत्राशंकंपुरस्तादुपवनतरवोदूरमाश्चेवगत्वा।एतेतस्मिन्निवृत्ताःपुनरपरककुप्प्रांतपर्य
स्तविंबेप्रायोभृत्यास्त्यजंतिप्रचलितविभवंस्वामिनंसेवमानाः॥१९॥इतिनिष्क्रांताःसर्वे।चतुर्थोंकः।ततःप्रविशतिलेखमलंक
रणस्थगिकांचमुद्रितामादायसिद्धार्थकः।हीहीमाणहे।कुद्धिजलंसिंच्चरेहिंसिंचंतीदेसकालकलसेहिंदंसेइहिकज्जफलंग
रुअंचाणक्कणीदिलदा॥१॥ताणहिदेमएचाणक्कस्सअज्जस्समंलिहिदोअमच्चरक्खसस्समुद्दालंछिदोसंगीदलेहोतस्सजेवमुद्दालं
२ इअंआछिदाआहरणपेडिआगहिदाकिलम्हिपाडलिउत्तंगच्छामि।परिक्कम्मावलोकयच।कहंखवणओआअच्छदिजावसेअसउण
भूदंदंसणंपहदुदंसणेहणापडिहरामि।ततःप्रविशतिक्षपणकः।खवणअ।अलिहंताणंपणमामिजेदेगंभीलदाएबुद्धीए।लोउत्तरेहिंलोए।

२१ सिद्धिं मे गो हिंगव्वादि।१। सिद्धा। भदंत वंदामि। क्षप। सावगा धम्मा सिद्धी मोडु। निव्वराय सावगा अध्ध ग्गारा सम्बुद्ध न लोएकस्स वव सा अ
विज्ञ न्तु मे पकरवामि। सिद्धा। कहं भदं [illegible] जो जाणादि। क्षप। सावगा किं एत्थ जाणिदव्वं एसो दे मगा दिसंको सलस्स कस्स पालो
लेहो त्तं चेदिं। सिद्धा। जाणादं भदंते णादे संतरदि पत्थिदो। ता वा हे दु भदंनो की रिसो अज्जादिवसो त्ति। क्षप। विहस्य सावगा मुंडिअ
मुंडो राकरुत्ताणि मुहुत्तं सि। सिद्धा। भदंत संपदं पि किंणादं तो के हि पत्थाणस्स उद्दस्स ऊ लंकु वि स्स दित्त दो गमिस्सं। क्षप।
सावग णं संपदं एदस्सिं मलअके दुकड एण अरुण्णुकु ले णाञ्च लेणवा अगि ही दमुद्दे णांग दी अदिं। सिद्धा। भदंत किं एदु दाणिं।
दुःअस्त्रअणि क्षप। सावगाणिसा मे हिं। पढमं दाव एत्थ कडए लोणं वा लिअ णिग्गमप वेसो आसि। दाणिं पञ्चासण्णे कुसुमउरे णा को वि अमु
द्दालंछि ओ णिग्गमिदुं पवेट्टुं वा अणुमोदी अदि ता जइ भागुराअणस्स सदालंछिओ णडलो ता गच्छ वीसद्धो अण्णहा राणाउ
क्खाविट्ठ। मा गुम्मा हिआरिएहिं संजमिअ कर चर णो राअउलं पवेसीअसि। सिद्धा। किं ण जाणादि भदंतो। अहाअ हंअमच्च रक्ख
सस्स सणिहिदो त्ति। ता अमुद्दालंछिदं पि मं णिक्कमंतं कस्स सत्ती णिवारेदुं। क्षप। सावग लक्खस सस्स पिसाचस्स वा केल को
होहिणाउ राए अमुद्दालंछिअस्स उ दे। णिग्गमो वा अ। सिद्धा। भदंत सल कुप्प। कज्ज सिद्धी मोडु। क्षप। उवासग्ग मोडु दे कज्ज सि राम.
द्धी अहं पि भागुराअणादो मुद्दं जाचेमि। इति निष्क्रांतौ प्रवेशकः। ततः प्रविशति पुरुषेणानुगम्यमानो भागुरायणः। स्वगतं। अ २१

मी १

हो वैचित्र्यमार्यचाणक्यनीतेः। मुहुर्लक्ष्योद्भेदा मुहुरधिगमाभावगहना मुहुः संपूर्णांगी मुहुरतिकृशा कार्यवशतः। मुहुर्नश्यद्वीजा मु
हुरपि बहु प्रापितफलेत्यहो चित्राकारा नियतिरिव नीतिर्नयविदः। ३। प्रकाशं। भद्र भासुरक न मां दूरीभवंतमिच्छति कुमारः। अतो
न्यर स्मिन्नेवास्थानमंडपे विन्यस्यतामासनं। पुरुषः। इदमासनं उवविसदु अज्जो। भागु। उपविश्य भद्र भासुरक पश्यः कश्चिन्मुद्रार्थी मां द्रष्टुमि मांर्
च्छतिस त्वया प्रवेशितव्य इति। पुरुषः। जं अज्जो आणवेदि त्ति निष्क्रांतः। भागु। स्वगतं। कष्टमेवमपि यदस्मासु स्नेहवान्कुमारो मलयकेतुर
तिसंधातव्य इति। अहो दुःकरं। अथवा। कुले लज्जायां च स्वयशसि च माने च विमुखः शरीरं विक्रीय क्षणिकधनलोभाद्धनवति ।
दाशां कुर्वाणो हितमहित मित्येतदधुना विचारातिक्रांतः किमिति परतंत्रो विमृशति। ५। ततः प्रविशति प्रतिहार्यनुगतो म तुद्
लयकेतुः। स्वगतं। अहो राक्षसं प्रति वितर्कबाहुल्यादाकुलामेव हि बुद्धिं पश्यं न मधिगच्छति। कुतः। भक्त्या नंदकुलानुरागदृढया नंदा मी
श्रयालंबिना चाणक्येन निराकृतेन कृतिना मौर्येण संधास्यते। स्थैर्यं भक्तिगुणस्य वा विगणयन्न किं सत्यसंधो भवेदित्यारूढकुला
लचक्रमिव मे चेतश्चिरं भ्राम्यति। ६। प्रकाशं। विजये क्व भागुरायणः। प्रतीहारी। कुमाल एसो क्खु कुमारस्स पादोप सेणक्कमिदु का मारीअ
मुद्दा सेपा दंसणस्स विद्धदि। मला। विजये मुहूर्तं तिष्ठ तावत्पदसं चाराभवया वदस्य पराङ्मुखस्येव यावण्णभ्यां नयनेपि दधामि। प्रतीहा
कुमारो आणावेदि। इति परिक्रम्य। पुरुषः। अज्ज एसो क्खु खवणओ मुद्दाणिमित्तं अज्जं पेक्खिदुं इच्छदि। भागु। प्रवेशय। पुरुषः। तह त्ति नि

२८ क्रांतः। प्रविश्य पुरुषः। रा०। कः धम्म विद्धी सावगाणं मो दु। भागु। नाचेनावलोक्य स्वगतं श्रेयेरा हसस्य मित्रं जीवसिद्धिः प्रकाशं। भदं
गार तः। न खलु राक्षसस्य प्रयोजनमेव किंचिदुद्दिस्य न्यते। रूप। संतं पावं सावगा तहिं गमिस्सामि सुहृद्यदा सिद्धिः प्रकाशं। भदंत
न खलु राक्षसस्य प्रयोजनमेव किंचिदुद्दिस्य मम्यते। रूप। संतं पावं सावगा तहिं ... तहिं लक्खवसस्स रा मं पिरासु गीआदि।
भागु। बलीयान् खलु हृदि प्रणयकोपः तत्किमपराद्धं राक्षसेन भदंतस्य। रूप। सावगाणा किं पि मह लक्खवसेणाअ वलद्धं सअं
अ बुहदा सो मदं भगो अत्तणो कम्मणा लज्जेमि। भागु। भदंत वर्ड्ढयसि मे कुतूहलं। मल। स्वगतं मम च। भागु। श्रोतुमिच्छामि। म
६६ ल। स्वगतं। अहमपि। रूप। सावगा किं शुणिणा अ सुणिदेव्वेण सुणिदे रा। भागु। यदि रहस्यं तत्तिष्ठतु। रूप। सावगा लहस्सं किं
दु अदिमुद्दं न दास्यामि। रूप। स्वगतं पुरुषमिदानीं मर्थिने कथयितुं। प्रकाशं। का गदिस्सुणाडु सावगा अत्थि दाव हगो मंद
भग्गो पढमं पाडलिउते णिवसमाणो लक्खवसेणामि त्तत्तणं उवगदे त्ति हिं अव सलेलक्खवसेणा गूढं विसकण्ण आपअो अ उ
व्याइअ घादिदेव वृद्धीसरे। मल। सवैक्लव्यं। आत्मगतं कथं राक्षसेन घातितस्तातो न चाणक्येन। भागु। भदंत ततस्ततः। रूप।
ह२ तदो गोलक्खस मित्तं त्ति कडुअ वाराणहहदगे णासरिाअआरं राअ रादो णिक्कासिदे एदाणिं वि लक्खवसेणा आरो अ कम्म कुस राम.
मित्तं तिकडुअ कासा वे हदगे णासरिाअआरं राअ ... लेणा किं वि त्तारिसं आरहदी अ दिजेणाहगो जी २८
णिसंसं। भागुराय। पदिन रहस्यं तत्कथ्यतां। रूप। णक्का सावगाणा छिंदिए अंतह विणा कहिस्सं। भागु। अहमपि प

श्रु१

अलो आदो विणिक्कासी आमि। भागु। भदंत प्रतिश्रुत राक्षस इम ... हणकेनेदमकार्यमनुष्ठितं न राक्षसेनेत्यस्माभिः
श्रुतं। रूप। कर्णौ पिधाय। संतं पावं सावगा चाणक्केण ... तं विसकण्णआए णामं पि ण सुदं। भागु। भदंत मुद्राद्धा यतो प
कुमारं श्रावय। मल। श्रुतं सर्वम वसाधिताः शौचः सुहृत्त्रुद्वाद्धि पुमधिकृत्य भाषितं॥ पितुर्वधव्यसनमिदं हि येन मे चिरादपि
गाथ४ द्विगुणमिव हितं।७॥ रूप। स्वगतं। अएसुदं मलअकेदुणा हदगे ... हंत किदं ... कोटिल्लाइ इति निष्क्रांतः। मल। प्रत्यक्षवदाकाशे
लक्ष्यं बध्वा। राक्षस २ युक्तमिदं। मित्रं ममेदमिति निर्वृतचित्तवृत्तिं विश्रंभतस्त्वयि निवेशितसर्वकार्यं। तातं निपात्य सह बंधुजनाश्रु
येरत्र्यर्थं तो विनतु राक्षस राक्षसोसि।८॥ भागु। स्वगतं रक्षणीयाः राक्षसस्य प्राणा इत्यार्यादेशः। भवत्वेवं तावत्। प्रकाशं। कुमार अ
लमावेगेन। आसनस्थं किंचित्कुमारं विज्ञापयितुमिच्छामि। मल। उपविश्य। सखे किमसि वक्तुकामः। भागु। कुमार इह खलु अर्थिना
व्यवहारिणां अर्थवशात् दरिमित्रोदासीनव्यवस्था न लोकिका न मिवेच्छावशात्। य तस्मिन्काले सर्वार्थसिद्धिं राजानमिच्छ
तो राक्षसेन दमनुष्ठितमिति नातिदोषो ... त्रिय पश्यामि। यस्य तु हि कुमारः स मित्र ... त्वमुपानयंती मित्रत्वमर्थवशादृ
शत्रुता नीति नेयस्य ततः पर्वतकोत्रं ज ... वजीवतएव पुंसः॥९॥ तदत्र पत्तति न्ने पालंभनीयो राक्षसः। आनंदराज्यलाभं तु पत्यतो मात्यार
त्वमपरतोऽपस्थ परियहे परित्यागे वा कुमारः प्रमाणं। मल। एवं सखे सम्यग्गृहीतवानसि। यतो मात्यवधे प्रकृतिक्षोभः स्यादेवं वं संदिग्धो
राक्षसस्य प्रमादपि वा यस्तायासु... तनामादेवः पर्वतेश्वर एवार्थपरिपंथामहान राति राप्तात्। तस्मिन्नु

२९ दिजपः। गुल्मस्थानाधिकृतान्त्वादिमयपुरुषः। दिजअङ्गुरकुमारो। अज्जगुम्मट्ठाणाधिकिदेदीहक्खेदो विसादेदि स्सेसत्तु अल्लेहिं
कडअदेशि। कमंतो अग्गदिद्मुद्दापुरिसो गहिदो तापच्चक्खी करेदु कुरंगअज्जो। माग। भद्र प्रवेशय। पुरु। तथेति निष्क्रांतः। ततः प्र
विशति बद्धपुरुषेणानुगम्यमानः संयतः सिद्धार्थकः। २ ख्गतं। आसंक्तीए गुणो सुंदो से सुपरंमुहं करंती ए। अम्हारिसाणं णीएस्सवामोमो कुणार
सामिभत्तीए। १ प्रकु०। अज्ज अअं सो पुरिसो। भागु। विलोक्य। किमयमागंतुकः आहोस्विदिहैव कस्यचित्परिग्रहसिंअज्ज अ
हं खु अमच्चरक्खस्स सेवओ। भागु। भद्र तत्किमर्थममुद्रहीतमुद्रः कटकान्निष्क्रामसि। सिद्धा। अज्ज कज्जगोरवेण तुवरावि दो
२ ङ्क्लि म्हि। भागु। कीदृशं तत्कार्यगौरवं यद्राजशासनमुल्लंघयति। मल। सखे भागुरायण लेखमुपनय। भागु। सिद्धार्थकहस्ताद्गृही
त्वा पत्रं मुद्रांकितं दृष्ट्वा कुमार अयं लेखः राक्षसनामांकितेयं मुद्रा। मल। मुद्रामपरिपालयन्नुद्घाट्य दर्शय। भागु। तथा कृत्वा दर्शय
ति। मल। वाचयति। स्वस्ति यथास्थाने कुतोपि कोपि किमपि [struck through] अस्मत्प्रतियोगिनिराकृत्य दर्शितं सत्य मलयवाक्ति ४
संधेन· सांप्रतमेतेषामपि प्रथममुपन्यस्तसंधीनां अस्मत्सुहृदां पूर्वप्रतिज्ञातसंबंधपरिपणप्रोत्साहनेन सत्यसंधः प्रीतिमु
त्पादयितुमर्हति। एतेप्येवमनुगृहीताः संतः स्वाश्रयविनाशेन चोपकारिणमाराधयिष्यंति· अविस्मृतमेतत्सत्यवतः स्मारया
मः एतेषां मध्यात्केचिदरेः कोशं दंडं अपामर्थिनः केचिद्विषयेण इति अलंकारत्रयं च सत्यवतानुप्रेषितं तदुपलब्धं मयापि लेख राम· २९
कमपि पुरुषविशेषमवगमयति।

८२ स्यापत्यार्थं किंचित्तु प्रेषितं तदुपगमनीयं वाचिकं चाप्तनमात्सिद्धार्थकाच्छ्रोतव्यमिति। मल। सखे भागुरायण कीदृशो लेखः। भागु। भ
द्र सिद्धार्थक कस्यायं लेखः। सिद्धा। अज्ज ण जाणामि। भागु। धूर्त लेखो नीयते न ज्ञायते कस्यायमिति सर्वं तावत्तिष्ठतु वाचि वार२
कं त्वत्तः केन श्रोतव्यं· सिद्धा· तुह्मेहिं। भागु। किमस्माभिः। सिद्धा। गिस्सेहिं गहिदो ण आणामि किं भणामि त्ति। भागु। सरोषं· एवं जा
नासि· भासुरक बहिर्नीत्वा ताडय तावद्यावत्सर्वं कथयति। पुरु। जं अज्जो आणावेदि त्ति सिद्धार्थकेन सह निष्क्रम्य पुनः प्रविश्य अज्ज
इअं मुद्दालंछिदा पेडिआ ताडिज्जंतस्स· भागु। विलोक्य कुमार इयमपि राक्षसमुद्रांकितैव। मल। सखे अयं लेखस्यास्य
स्यार्थो भविष्यति। इमामपि मुद्रां परिपालयन्नुद्घाट्य दर्शय· भागु। तथा कृत्वा दर्शयति· मल। सखे अयं लेखस्य संप्रत्यार्थो भविष्यतीत्य
लंकरणं विलोक्यात्मना प्रेषितं रत्नाभरणं मया स्वशरीराद्अवतार्य राक्षसाय यत्प्रेषितं· व्यक्तं चेदं राक्षसलेखः। भागु। एवं निर्णी
यत एव संशयः। भागु। भद्र पुनरपि ताड्यतां। पुरु। जं अज्जो आणावेदि त्ति निष्क्रम्य सिद्धार्थकेन सह पुनः प्रविश्य एसो क्खु
ताडिज्जमाणो भणादि· कुमारस्स जे वणिदेदेमि त्ति· मल। तथा भवतु। सिद्धा। पादयोर्निपत्य अभएण मे पसादं करेदु अज्जो
। मल। भद्र अभयमेव परवतो जनस्य· निवेद्यतां यथावस्थितं· सिद्धा। सामे दु कुमारो अहं खु अमच्चरक्खसेन इमं लेखं द
दुअ चंदउत्तसआसं पेसिदो। मल। वाचिकमिदानीमाप्तमिच्छामि। सिद्धा। कुमाल अहं अमच्चरक्खसेण संदिट्ठो जहा मम पिअव

३· वसुमित्रस्तापरथयराज्ञरागोन्तरस्य हस्तमुष्पस्तसंधारणं नंजहान्कुलत्दाहिवोचित्तयम्मा मल अरगलाहिवोसीदेनारोकी रेदमरागोसैपु हो१
करठरवर्तोसिंधुराओसिंधुसोणोपारसीओ भेहरणादोएत्ताहेरेदेय टमगदिदाति सिरा अरागो मह अवेकेदुरागो विस अभिवंदि·
अवरेविहत्तिबलंतंजहाचारा छंसिराकरिअमहाभाएगामरुपी दीउप्यादिदात हायदोसीविपदमभारिरोदा अत्थोसंपादयि गंं२
दचोत्तिएदिसेगारा अंसंदेसोनलस्वगतोकथं विन्नवमदियापिमामभिदुत्वेति· अपवाअतएवराहसेनिरतिकापारीति·अका
ग५ पोदिशयेराकुसंद्रष्टुमिच्छामि। प्रती। जंकुमारो आणवेदित्ति निष्क्रांता। ततः प्रविशत्यासनस्थः स्वभवनगतः पुरुषेण सह
सचिं तोराकुः २ आत्मगतं। संपन्नमप्पस्महद्भलंचेंद्रगुप्तवतेः संप्रति तमि तियत्तःतंनेममनमेसः परिसुद्धिरस्ति। कुतः साध्येनि
श्चितमचपेनघटितेबिम्बस्वपदेस्थितिं प्यावंत्रेचविपहृतोभवति यत्नस्साधनंसिद्धयोयत्सा ध्येस्वयमेवतुल्यमुभयोः परे
विरुद्धंवयत्नस्योगीकरणेनवादिनद्वस्यात्साभिनोनियहः। अपवाविज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापेः परिरागि
मिनिनाधिकस्यपितमहामि। प्रकाशं। भद्रप्रियंवद·उच्चंतामस्मद्वचनात्कुमारानुयायिनोराजानश्च संप्रतिदिष्ट्या २ प्रत्यासीदति
कुसुमपुरं येनतस्य रिकल्पितविभागैर्भवद्भिः प्रयाणंप्रयातव्यं। कथमिति। [illegible] प्रस्तातव्यं पुरस्तात्स्हमग
धगणोममिनुयत्यसेन्येगंधारेर्मध्ययानेयवननृपतिभिः संविधेयः प्रयत्नः। पश्चात्तिष्ठेतुधीराः शकनरपतयः संभृताश्च। एम·
३·
राक्षसः। कोत्रभोदवारिकः। प्रविश्य पुरुषः। आज्ञापयतुअमात्यः। राक्षसः। मद्भोकुमार·कुमारं। पुरुषः। जं अमच्चो आणवेदित्ति निष्क्रांतः। प्रविश्य प्रतीहारी। भट्ठ१
अत्र दुरअमच्चो अमच्चइच्छदि तुमंकुमारोपेक्खिदुं। राक्षसः। भद्रेमुहूर्तं तिष्ठ। कः कोत्र भोः। प्रविश्य पुरुषः। आणवेदुअमच्चो। राक्षसः। उ
च्यतामस्मद्वचनात्त्कटकदासः यथा वयंकुमारेणाभरणानि परिधापिताः स्ततयुक्तमनलंकृतैः कुमारस्य र्शनमनुभवितुं। अतो
यत्तदलंकरणत्रयंक्रीतं तत्रमध्यादेकंदीयतामिति। पुरुषः। जं अमच्चो आणवेदित्ति निष्क्रम्य पुनः प्रविश्य अमच्च एदं आभरणं।
राक्षसः। नाट्येनात्मानमलंकृत्योत्थाय च भद्रेराजगृहोपगामिनं मार्गमादेशय। प्रती। एदुअमच्चो। राक्षसः। आत्मगतं अधिकारपदं
हिनामनिर्दोषस्यापि पुरुषस्यमहदाशंकास्थानं। कुतः। भयं तावत्सेव्यादभिनिविशते सेवकजनं ततः प्रत्यासन्नाद्भवति हृदये भाद
चैवस्थितमिवतोमस्यमहतावनिदिते। ततोध्यारूढानांपदमनुजनद्वेष जननं मतिः सोच्छ्रायाणांपतनमनुवेलंकलयति। १३। परिक्रम्य थ५
प्रती। हारी। अमच्च अअं कुमारोचिट्ठदिउवसप्पदुणं। राक्षसः। नाट्येनावलोक्य। अपंकुमारस्तिष्ठति। य एषः। पादाग्रेदत्तामवधायनि
श्चलांगीमनन्यत्वादयरिगृहीनतदर्शियष्यां। वक्रेंद्रुंयहति कर्णेरणदुर्वहाराणां कार्याणांकृतमिवगोरवेरणनम्रं। १४। उपसृत्य विजयतां
कुमारः। मल। आर्य अभिवादयेइदमासनमास्यतां। राक्षसः तथा करोति। मल। आर्य चिरदर्शनेनार्यस्य वयमुद्विग्नाः। राक्षसः।
कुमारव्यापारोपप्रतिविधानमनुतिष्ठतामयाकुमारादयमुपालंभोधिगतः। मल। आर्यप्रयाणोकथंप्रतिविहितमिच्छामि। राक्षसः।
त्रिश्रोतुर

३१ कुमारएवमादिष्टाःकुमारस्यानुयायिनो राजानः। प्रस्थातव्यं पुरस्तादिति पठति।मलः।स्वगतं।कथंवृएवमाद्दिनामेनचंद्रगुप्तमा
राधयितुमुपत्तात्सएवमांपरिचरतीति।प्रकाशं।आर्य आसीत्कश्चित्रः कुसुमपुरंगच्छति।राक्ष।पर्यवसितमिदानीं गतागतेनक
तिपयैरेवाहोभिर्वयमेवतत्रगंतारः।मलः।स्वगतं।युज्यते।प्रकाशं।नत्विदं।अयं कः।राक्ष।विलोक्य।अयेसिद्धार्थकः।भद्रकिमिदं।सि
द्धार्थकः।सबाष्पं लज्जां नाट्यन्नधोमुखस्तिष्ठति।राक्ष।भद्रकथय किमिदं।सिद्धा।सभयं।प्रसीदतु अमात्यः।नाडीघंलेनामएरा
पादिदंरहस्यंधारितुं।राक्ष।भद्रकीदृशंरहस्यमिति नखल्ववगच्छामि।सिद्धा।ननुविज्ञापयामि।ताडीअंतेनामएरापादिदंरहस्यंधारि
तुंअमात्यस्यइत्यर्द्धोक्ते सभयमधोमुखस्तिष्ठति।मलः।भागुरायणस्वामिनः पुरस्ताद्भीतो लज्जितो वानैषकथयि
ष्यति।अतः स्वयमेवार्यायकथय।भागु।यदाज्ञापयति कुमारः।अमात्य एषकथयति यथाहममात्येन लेखं दत्वा वाचिकं संदि
ष्टचंद्रगुप्तसकाशंप्रेषित इति।राक्ष।भद्रसिद्धार्थकअपिसत्यं।सिद्धा।लज्जां नाटयति।एवंअतिनाडीअंतेनामएरागिवेदिदं।राक्ष।
भद्रसिद्धार्थकअपिसत्यं।सिद्धा।लज्जांनाटयति।कुमारअनृतमेतत्।ताड्यमानःपुरुषःकिमिव नब्रूयात्।मलः।सरोषं।भागुरायणदर्शी
यलेखंवाचिकमेषभृत्यःकथयिष्यति।भागु।अमात्यअयंलेखः।राक्ष।कुमारशत्रोःप्रयोगएषः।मलः।लेखस्याभरणार्पणमार्य
शोद्धुमाभरणजातंप्रेषितंतत्कथंशत्रोः प्रयोगएषः।राक्ष।आभरणं निर्वर्ण्य।कुमारेणेदं मन्ममानुप्रेषितं मयाप्येतत्कस्मिंश्चित्प राम. ३१

रितोषस्थानेसिद्धार्थकायप्रदत्तं।भागु।ईदृशस्यविशेषतःकुमारेणात्मगात्रादवतार्यप्रसादीकृतस्येयंपरित्यागभूमिः।मलः।वाचिक
मप्यार्येणसिद्धार्थकाच्छ्रोतव्यमितिलिखितं।राक्ष।कुतोवाचिकं कस्यवावाचिकं लेखएवास्मदीयो न भवति।मलः।इयं तर्हि क
स्यमुद्रा।राक्ष।कपटमुद्रामुत्पादयितुं शक्नुवंति धूर्ताः।भागु।कुमार सम्यगमात्योविज्ञापयति।भद्रकेनायंलिखितः।सिद्धार्थकेनाव कहू
लिखितो लेखः।सिद्धा।राक्ष।समुखमवलोक्य तूष्णीमधोमुखस्तिष्ठति।भागु।भद्र अलं पुनरात्मानं ताडयितुं।कथय।सिद्धा।आर्य श
कटदासेन।राक्ष।कुमारयदि शकटदासेन लिखितो लेखस्तदाऽमयैव।मलः।विजयेप्रशकटदासं द्रष्टुमिच्छामि।प्रती।जं कुमारो आणा
वेदित्ति।भागुरायणः।स्वगतं।नखल्वनिश्चितार्थमार्यशकटदासं मलः।विजये शकटदासं द्रष्टुमिच्छामि।प्रती।जं कुमारो आणावेदि।लवनिश्चितार्थमार्य खद
चाणक्यप्रणिधयोभिधास्यंति।प्रकाशं।कुमारसकटदासप्रत्ययशकटदासो सोस्यस्याक्षरैर्मयालिखितइति प्रतिपत्स्यते।नतस्य ता५
तिलिखितमानीयतां वर्णसंवाद एवैनं निर्णाययिष्यति।मलः।विजये एवंक्रियतां।प्रती।कुमार मुद्दंचि।मलः।उभयमप्यानीयतां।
प्रती।जं कुमारो आणावेदित्ति निष्क्रम्य पुनः प्रविश्य कुमार इमं तं सअडदासेणसहत्थलिहिदं पत्तअं मुद्दा वि।मलः।
उभयमपि नाट्येनावलोक्य आर्य संवदंत्यक्षराणि।राक्ष।स्वगतं।संवदंत्यक्षराणि।शकटदासस्तु मित्रमिति विसंवदंत्यक्षराणि।किंतु सर
शकटदासेन।स्मृतं स्यात्पुत्रदाराणां विस्मृतस्वामिभक्तिना।चलेषु यशस्सु लुब्धेन न यशस्सु न पाषिपु।१५।अथवा।कःसंदेहः।मुद्रातस्य के

ग्र५ स्वर

३१ रांगुलिप्रणयिनी सिद्धार्थकस्तत्सुहृत्क्रमेणैवापरलिखत्स्त्विति तमिदं लेखं प्रयोगाप्रयं स्वयमेव शकटेन भेदपटुभिः संधाय सांईपेरे
र्भर्तस्तेह परामृष्टो रेवन सत्पदां प्राणार्थिनावेष्टितं । २६। मल । आर्य अलंकरणत्रयं श्री मलयस्तुत्रेषितं तदुपगतमितिमयस्त्रिरिवितं त
न्मध्यात्किमिदमेकं निर्वर्त्यत्यागतं । कथं तातेन धृतपूर्वमिदमाभरणं । प्रकाशं । आर्य कुतोयमलंकारः । राक्ष । वणिग्भ्यः क्रयादधिग
तः । राजा । विजये अपि प्रत्यभिजानासि भूषणमिदं । प्रतीहारी निर्दिश्य । सबाष्पं । कुमाल लक हं ... अभिजाणामि । संस्तदं मंसुगिदीदणा मैदे
तानि ५ व्वपवडीसरेण धारिदपुव्वं । मल । सबाष्पं । हा तात हा तात । एतानि तव वल्लभभूषणानि स्वगात्रोचितानि कुलभूषण गात्र प्रणानि । येः प्राभितो
सिमुखचन्द्र इत्र तावलासोनक्षत्रवानिव शरत्समयप्रदोषः । १७। राक्ष । स्वगतं । तत्कथं पर्वतेश्वरेणाधृतपूर्वाणीत्याह । व्यक्तमेवास्य भ
षणानि [redacted] चाणक्यप्रयुक्तेन वणिग्व्यंजनेनास्मासु विक्रीतानि । मल । आर्य तातेनधृतपूर्वाणामाभरणविशेषाणां
विशेषतश्चन्द्रगुप्तहस्तगतानां वणिग्भ्यः क्रयादधिगम इति न युज्यते । अथवा युज्यत एवैतत् । कुतः । चन्द्रगुप्तस्य विक्रेतुरधिकं लाभ
मिच्छतः । कल्पितं मूल्यमेतेषां क्रूरेणाभवता वयं । राक्ष । स्वगतं । अहो सुश्लिष्टोभस्य प्रयोगः । कुतः । लिखितो यं न मयेति नोत्तरमिदं मुद्रा
मदीया यतः सौहार्दं शकटेन खण्डितमिति श्रद्धेयमेतत्कथं । मौर्यो भूषणविक्रयं नरपतौ को नाम संभावयेत्तस्मात्संप्रतिपत्तिरेव
हि वरं न प्राम्यमत्रोत्तरं । १५। मल । एतदार्यं पृच्छामि । राक्ष । सबाष्पं । कुमारय आर्यस्तं पृच्छ वयमिदानीमनार्याः संवृत्ताः । मल । मौर्यो राम. ३१

२१

स्वामिपुत्रः परिचारणपरोमित्रपुत्रस्तवाहं दाता सोर्थस्य तु भ्यं स्वमतमनुगन्तस्त्वं तु मत्यं दशसि । दास्यं सत्कार पूर्वं न नु सचिवपदं तत्र ते मुद्रा १
स्वाम्यमत्र स्वार्थे कस्मिन्नमीहा पुनरधिकतरे त्वामनार्यी करोति । राक्ष । कुमार एवमभियुक्तव्यवहारेणाचेममवैतेषा निर्णयो
दत्तः । कुतः । मौर्यो सौ स्वामिपुत्र इति तेदेवपठति । मल । लेखमलंकरणस्थगितं चनिर्दिश्य । किमिदं । राक्ष । विधेर्विलसितमिदं
न चाणक्यस्य । कुतः । भृत्यत्वे परिभावधामनि सति स्नेहात्प्रभूणां सतां पुत्रेभ्यः कृतवेदिनां कृतधियां येषामभिन्नावयं । तेलो
पेन ५ कस्य परीक्षकाः क्षितिभृतः पापेन दृष्टास्तस्येदं विपुलं विधेर्व्यवसितं तेषां प्रयत्नच्छिदः । २१। मल । सरोषं । किमद्यापि निह्नूयते र्य
विधेः किलेतद्विलसितेन सा वियोग लोभस्य अनार्य । कन्यां तीव्रविषप्रयोगविषमां कृत्वा कृतघ्नस्त्वया विस्रंभप्रवणः पुरा मम पिता
नीतः कथाशेषतां संप्रत्याहितगौरवेण भवता मंत्राधिकारे रिपोः प्राणाः प्रागपरेण मांसवदहो विक्रेतुमेतेवयं । २२। राक्ष । स्वगतं । अ र.आ: ५
यमपरो गंडस्योपरि विस्फोटकः । प्रकाशं । कर्णौ पिधाय । शांतं पापं नाहं पर्वते श्वरे विषकन्यां प्रयुक्तवान् । मल । केन तर्हि व्यापादित
ध्यंर् स्तातः । राक्ष । दैवमत्र प्रष्टव्यं । मल । दैवमत्र प्रष्टव्यं न क्षपणको जीवसिद्धिः । राक्ष । स्वगतं । कथं जीवसिद्धिरपि चाणक्यस्य प्रणिधिः ।
हंत रिपुभिर्मे हृदयमपि स्वीकृतं । मल । सक्रोधं । भासुरक आज्ञाप्यतां शिखरसेनः सेनापतिः । य एते राक्षसेन सह सुहृत्त्वामुत्पाद्य
अस्मच्छरीरमभिद्रोहेणाचंद्रगुप्तमाराधयितुकामाः पंचराजानः । तद्यथा । कौलूतश्चित्रवर्मा मलयाधिपः सिंहनादः काश्मीरः पुष्क

गं।

३२ राज्ञः सिंधुराजः स्वयं राज्ञः पारसीकाधिपो मे पंडति तत्र त्रयः प्रथमं मदीयां भूमिं कामयंते ते रंभीरंभ्रमभिनीयपांसुभिः प्रर्थितां।
ऽतरोत्तरगरूक्तिवलकामुकौ हत्तिनैवव्यापाद्यतामिति। उरुराजे कुमारो आरागवे दिन्निमिक्रांतः मल। राक्षसनाहं विसं भवाली
ए हसः मलयकेतुः खलु इंतह खसमाम्नीयतां सर्वी मनात्वया चंद्रगुप्तः। पश्य। विष्णुगुप्तंचमोर्यं च समम पागतोत्वया। उन्मू
।नेमंमि:४ लयितुमीशोहं विदर्भमिव दुर्नयः। भागुरायणः। कृतं कालहरणेन सांप्रतं कुसुमपुरे रोधाय आज्ञाप्यतामस्म हलानि। गौडीनां लो
ध्रधूलीपरिमलबहलाव धूम्रयंतैः कपोलाव्रुंकिम्नंतः क्लिमानंभ्रमरकुलरुचः कुंचितस्यालकस्य। पांसुस्तंवावलानां तुर
गखुरपुटक्षोदलब्धास्पदाभाः शत्रूणामुत्तमांगे गजमदसलिलक्लिन्नमूलाः पतंतु। २४। सपरिजनो निष्क्रांतो मलयकेतुः। राक्षसा
वेगं हा धिक्कष्टम् आतितां श्रित्रवमदिपक्षपस्विनः तत्कथं सुहृद्विनाशाय राक्षस प्रवृत्तेन मया तुनाशायः तत्किमिदानीं करवाणि
मंदभाग्यः। किं गच्छामि तपोवनं न तपसा शाम्यत्य सवैरं मनः किं भर्तृन नुयामि जीवति रिपौ स्त्रीणामियं योग्यता। किं वा खड्गसखः
पताम्यरिबलेनैतन्नयुक्तं भवेच्चेतश्चंदनदासमोक्षरभसं रुंध्यात्कृतघ्नं न चेत्। २५। इति निष्क्रांताः सर्वे पंचमोंकः। ततः प्रविश
त्यलंकृतः सिद्धार्थकः। जअदि अजअ जलदणीलो केसवो केसिघाई जअदि अ जणदिट्ठीचंदमा चंदउत्तो। जअदि अजअ आसणसज्जं जीअ राम.
काऊणसे संपडिहदपडिवक्खा अज्जचाणक्कणीदी। ४। जाव चिरस्स कालस्स पिअवअस्सं समिद्धत्थअं अण्णेसामि। परिक्रम्या ३२

वलोक्य च एसो सो पिअवअस्सो समिद्धत्थओ इदो ज्जेव आअच्छदि। जाव णं उवसप्पामि। ततः प्रविशति समिद्धार्थकः। संभावंता
आवाणअरेसु गेहसवेसु आवंता हिअअट्ठिआ णाविरहवाविरहे मित्ताराहमंति। ५। सुदं मए जधा मलअकेदुकडआदो पिअवअ
स्सो मे सिद्धत्थओ आगदोत्ति। ता जाव णं अण्णेसामि इति परिक्रामति। विलोक्य। एसो सो सिद्धत्थओ। उपसृत्य सिद्धत्थअ अविसुह
पिअवअस्स सिद्धा विलोक्य कथं पिअवअस्सो समिद्धत्थओ उपगम्य आदि सुहं पिअवअस्सो। उभावन्योन्यमालिंगतः। समि
द्धत्थओ सुहं जेरा तुमं चिरपवासपच्चागदो विअ ज्जा विरा मे गेहं गच्छसि। सिद्धा। पसीदह दु पिअवअस्सो दिट्ठमेत्तो जेव्व मि अज्ज
चाणक्केण आणत्तो जधा सिद्धत्थअ गच्छ एदं पिअदंसणं पिअदंसणस्स देवस्स चंदसिरिणो णिवेदेहि त्ति। तदो तस्स णिवेदिअ एद अ
णुहूदपत्थिवप्पसादो अहं पिअवअस्सं पेक्खिदुं तव गेहं चलिदो म्हि। समि। वअस्स जदि मए विस्सुणिदव्वं तदो कधेहि किं तं पिअं जं पिअ
स्स४ दंसणस्स णिवेदिदं। सिद्धा। वअस्स किं तव वि अकहिदव्वं अत्थि। ता णिसामेहि। अत्थि दाव चाणक्कणीदिमोहिद
मदिणा मलअकेदुहदएण णिराकरिअ लक्खसं हदा चित्तवम्मप्पमुहा पंच पत्थिवा। तदो असमिक्खिदकारी एस
सो दुराआरोत्ति उज्झिअ मलअकेदुहदअं अत्तणो कुसलदाए भअदिलोलसेसकदपरिवारेसु सकसकविसअं पत्थिदेसु सा
मंतेसु भद्दभडपुरिसदत्तडिंगिरादवलउत्तराअसेणभागुराअणरोहिदक्खविजअवम्मप्पमुहेहिं गहिदो मलअकेदू। समि। व

३४ ग्रस्ताभद्दभडप्पमुहाकिलदेवस्सचंदसिरिरोग्रवरन्नामलग्रकेउंसमासिदन्निलोएमंतीग्रदिनाकिंतिामित्तुंकुकविकग्र
राग्राडग्रस्तविग्रग्रसंमुहेग्रसंतिाव्वहरोसिद्धा।वग्रस्सग्रमुतिाग्रगदीएगामोचारगाकराीदीए।समि।तदोशसिद्धा।तदोयह
दसारसाहरगासमेदेराइदोतिाकमिग्रग्रज्जचारगाकेरगपडिवक्खसग्रलराग्रलोग्रसेसंरिडवलं।समि।वग्रस्सकहिंतं।सिद्धा॥
जहिंएदेग्रदिसग्रगरुएरांदारगादप्पेरादंतीसजलजलदगीलाग्रोभमंतारगादंति।कसपहरमएरांजाग्रकेपाष्फुराग्राग ए४
हिदजग्रगासन्नासंपवंतेमुलंगा।३।समि।वग्रस्ससचंदावविवडुत्तहासवलाग्रपव्वकवंडजिग्रगराहिग्रोरोचिरंवि वित्रग्र
ग्रज्जचाणकोकिंपुरोसितंजेवमेतिपदमारूढो।सिद्धा।वग्रस्सग्रदिमुद्दोसिदाणिंतुमंजोग्रमव्वरकरवसेरादिग्ररावगादि
ग्रपुव्वंग्रज्जचारगकबुद्धिंग्रवगाहिदुमिच्छसि।समि।वग्रस्सग्रमव्वरकरवसोसंपदंकहिं।सिद्धा।वग्रस्ससोकवुलसिंहग्रवि
लोलेवहमारोगमग्रग्रकेउकडग्रारोतिाकमिग्रउंदुरराग्रमहेएरगाचरेराग्रराउसंधीग्रमारोगाइमंपाडलिउत्तंग्रागदोत्तिग्रज
चागाकस्सतिावेदिदं।समि।वग्रस्सतधारगामग्रमव्वरकरवसोगंदरज्जपब्भारगाग्ररोगकिदववसाग्रोतिाकमिग्रसंपदंग्र
किदत्थोपुरोगविइमंपाडलिउत्तंग्राग्रदोजेव्वोसिद्धा।वग्रस्सतकेमिचंदगादासससिरोहेरोत्ति।समि।वग्रस्सचंदगादासस्स
मोकरवंपेक्खदि।सिद्धा।सिद्धा।वग्रस्सतकेमिचंदगादासविरोहेरोत्ति।समि।वग्रस्सचंदगादासस्सपोक्खपेक्खदि।सिद्धा।कु राम. ३४

देसेग्रधसमत्तमोक्खो।सोखुसंपदंग्रज्जचारगाकस्सग्रारगात्तीएकुविहिंविवज्जहारगांपवेसिग्रवावाइग्रहोग्रम्हेहिं।समि।सको
धांकिंग्रज्जचारगकस्सधादग्रजरोगग्रसेसगाहिं जेराग्रम्हेईरिसेसुणिग्रोएसुणिग्राजंग्ररिशिासंसेसुासिद्धा।वग्रस्सकेजी
वलोएमीविदुकामाग्रज्जचारगकस्सग्रारगात्तिंपडिऊलेंति।गाएहिंचंडालवेसधारिरोगाभविग्रचंदगादासंवज्जट्ठागंगाग्र
मोउभोणिक्कांता।प्रवेशकः॥ततःप्रविशतिरज्जुहस्तःपुरुषः॥छगगुगाजोग्रदिढाउवाग्रपरिवाडिघडिग्रपासमुही।चारगाकरा
ढूरग्रग्ररिग्रसंजमराउग्रुग्राजग्रडाधाएसोसोपदेसोग्रज्जचारगकस्सपुरग्राउंदुरराकहिदोजहिंमरग्रज्जचारगक्कारात्तीएग्रम ब्रु
रकरवसोपेक्खिदव्वोदिलोकयकधंएसोकवुग्रमव्वरकरवसोकदावगुंव्वरोगाइरोजेव्वग्राग्रवदि।ताजाववजिस्सुजाराणादेविहिंग्र
तरिदसरीरोपेक्खामिकहिंग्रासरायरिगाहंकेरादित्तिःपरिक्रम्यावस्थितः॥ततःप्रविशतियथानिर्दिष्टःसशस्त्रोराक्षसः२सात्तं
८ग्रय कएंभोःकष्टं।उव्विवाग्रकात्तेरवकुलदागोज्ञांतरंग्री गिताताभेवागुगता गतानुगतिकास्तवकात्तुरागाःप्रजाः॥ग्रहोरप्पमंचा
ग्रयोरुपकलेःकार्येस्वक्षरुजितािकिंकुर्मस्तपवोलमांगरहितेरंगेःकपेस्थीवते।५।ग्रपिचापातिग्रल्कोदेवंभुजनपातिमुक्ते३
भिजनेगतािक्षिदेशग्रग्रीईपलमविनीतेवव्वपली॥स्थिरीभक्ताचासिमकिमिहकरवागिस्थिरमपिप्रयत्नमनोयेषांविफलयति ४२
देवंदिवपदिवाधममाहीदेवेगतेदिवमनुद्विषमनुष्योज्पेषोलम्बरंतमधिकृतसकृतःप्रयत्नः॥तस्मिन्हतेननवमस्पतयाप्यसि

३५ द्विर्दैवं हि हंतं दकुलशत्रुरसौ न विप्रगः अहो विवेकशून्यता म्लेच्छस्य । कुतः । यो नष्टानपि श्रीवनाशामधुनाप्यनुष्ठवनेत्ताभिनस्तेषां
वैरिभिरहतः कथमसौ संधास्यते राक्षसः । एतावद्धि विवेकशून्यमनसा म्लेच्छेन नालोचितं दैवेनोपहतस्य बुद्धिरथवा सर्वस्य
र्यस्यति ॥ ५ ॥ तदिदानीमपि तावदरातिहस्तगतो विनश्येन्न राक्षसश्चंद्रगुप्तेन सह संधिं कुर्यादिति विरमनायासेन शत्रुणापरि
भूत इति । समंतादवलोक्य । सास्त्रं । एतास्ताः देवपादाः कमणपरिचयपवित्रीकृततलाः कुसुमपुरोपकंठभूमयः । इह हि चापाकृ
ष्टिर्विमुक्तप्रशिथिलकविकाग्रहे रात्रदेशे देवेनाकारि सर्वप्रजविततुरगंवाणमोक्षलेख्या । अस्यासु धानरगौष्ठितमिह क
थितं राजभिस्तैर्दिने त्वं संप्रत्यलोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयंति ॥ ६ ॥ तत्कांबरलुगच्छामि मंदभाग्यः । विलोक्य भवतु र क्षे६
दृष्टमेतज्जीर्णोद्यानं अत्र प्रविश्य कुतश्चिद्वृत्तांतस्य वृत्तांतमुपलप्स्ये । परिक्रम्य अहो अलक्षितोपनिपाताः पुरुषाणां स
मविषमदशाविभागपरिणतयो भवंति । कुतः । पौरैरंगुलिभिर्नवेंदुवदहं निर्दिश्यमानः शनैर्यो राजेव पुरा पुरान्निरगमं राज्ञां
सहस्रैर्वृतः । भूयः संप्रति सोऽहमेव नगरे तत्रैव वंध्यश्रमो जीर्णोद्यानकमेष तस्कर इव त्रासाद्विशामि द्रुतं ॥ ७ ॥ अथवा । येषां प्र
सादादिदमासीत्त एव न संप्रति । नाथेन प्रविश्यावलोक्य च । अहो जीर्णोद्यानस्यानिरतिशयता । अत्र हि । विपर्यस्तं सौधं कुल
मिव महारंभरचनं सरः शुष्कं साधोर्हृदयमिव नाशेन सुहृदां । फलैर्हीनाः वृक्षा विगुणनृपयोगादिव नयास्तृणैश्छन्ना भू राम. ३५

तोर
॥ मिर्मतिरिव कुनीतेरविदुषः ॥ ८ ॥ अपि च । क्षतांगीलांगीनां तीव्रैः परशुभिरुदग्रक्षमभृतां रुजा कूजंतीनामविरतकपोतोपरुदितैः । स्वनि
र्मोकच्छेदैः परिचितपरिक्लेशकृपया श्वसंतः शाखाभ्रं व्रणमिव निबध्नंति फणिनः ॥ ९ ॥ एते च तपस्विनः । अमी ते शरीरपरिशोषमनु
भवंतः कीटक्षतिं अश्रुचमिवानिरुद्धं वहंतः । छायावियोगमलिना व्यसने निमग्ना व्याधाः श्मशानमुपगंतुमिव प्रवृत्ताः ॥ १० ॥ याव
दस्मिन्विषमदशापरिणमत्तुलमेभि शिलातले मुहूर्तमुपविशामि । उपविश्य । आकर्ण्य च । अये तत्किमिदमस्मिन्काले पटुप
टहशंखमिश्रो नांदीनिनादः । य एषः । प्रकटहरवशात्रोत्ताणां श्रुतिपथमसारं गुरुतया बहुत्वान्न प्रासादैः सपदि परिपीतोऽपि तदवाप्य
सौनांदीनादः पटुपटहसंसार्यविनितो दिशो द्रष्टुं दैर्घ्यं प्रसरति सकौतूहलमिव ॥ ११ ॥ विचिंत्य आः भवतु ज्ञातं एष हि मलयकेतुसंयम
नकृतं राजकुलस्य स्पर्धेर्ष्याकोनाधिकं मौर्यकुलस्य परितोषं विभावयति । सबाष्पं । कष्टं भोः कष्टं । श्राविता सिरिश्रियं मत्तोऽरिभिर्नी
य च दर्शितः । अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः ॥ १२ ॥ पुरुषः आसीनो एषोऽत्र आर्यजाबकाज्जचाणक्याणत्तिं संपादेमि । इति राक्षसम
पश्यन्निव तस्याग्रतो रज्जुपाशेनात्मानमनुबध्नाति । राक्षसः दृष्ट्वा अये कथमात्मानमनुबध्नाति अयं चाहमिव दुःखितस्तपस्वी
भवतु पृच्छाम्येनं । भद्र किमनुष्ठीयते । पुरुषः सबाष्पं । अज्ज पियवअस्सविरहदुःखिदो अम्हारिसो मंदभाओ आरंभदि हुदि । राक्षसः आ म
गतं । प्रथममेव मया ज्ञातं । नूनमहमिवार्त्तस्तपस्वीति । भवतु पृच्छाम्येनं । प्रकाशं । हे व्यसनसब्रह्मचारिन्यदि न गुह्यमतिभारि

३६ कं वा ततः श्रोतुमिच्छामि। पुरु॰। अज्ज ज्ञरागरहस्संसारा अ अ इगरुअं किं दुराससु कुरोमि पिअवअस्स विरासदुःखिद हिअओ रत्ति
अमे न्निविमलरास्सकालहररां काढुं। रा॰। निःश्वस्य आत्मगतं। कष्टं एतेसु तह्यसेनपुपाँवदु र्तेना। अत्यादिपा महेदवपमेने
प्रकाशं भद्र यदि न रहस्यं नातिगुरु कं वा ततः श्रोतुमिच्छामि। पुरु॰। अहोणि दंधो अज्ज ज्ञस्स कागई सिवेदेमि अत्थि रावरस्थ्या
अरेमणिअरा रेसठी जिह्णुदासो णाम। रा॰। आत्मगतं। अः अस्ति जिष्णुदासो नाम चंदनदासस्य परमसुहृत्। भवन्तु प्रकाशं ततः सु ४
किं तस्य। पुरु॰। सोम अपि अवअस्से। रा॰। सहर्षमात्मगतं। प्रियवयस्य इत्याह अतं तस्मिन् रु छः संबंधः। ज्ञास जिं वंदनदासस्स
वृत्तांतं। पुरु॰। सो दाणिं संपदं दीणजणादिस्स विहवो जलणं पविसिदुकामो णअरादो णिक्कंतो। अहं पि णाम वत्तस्सअसुहासिदं बंधु
सुणामि ताव अत्ताणं वावादइदुं इमं जिण्णुज्जाणं आगदो। रा॰। भद्र अथ अग्निप्रवेशे प्रियसुहृदस्ते को हेतुः किं मोखपथातिगेन
महता व्याधिना। पुरु॰। अज्ज ण। रा॰। किं अग्निविषकल्पेन नरपतेर्निरस्तः कुधा। पुरु॰। अज्ज संतं पावं अज्ज वंदउत्तस्स
जणवदे अणिसंसा पडिवत्ती। रा॰। अलभ्यमनुरक्तवान् कथय किं नु नारीजनो। पुरु॰। कंणं पिधाय अज्ज संतं पावं अभूमी एसो
सो विणआरस्सवसीकदस्स सेट्ठिजणस्स विसेसदो जिह्णुदासस्स। रा॰। ससः। किमस्य भवतो यथा सुहृद एव नाशो विधिः। (२४) पुरु॰। अ राम॰
ज्ञ अधइं। रा॰। सोद्वेगमात्मगतं। चंदनदासस्य प्रियसुहृदु इति तदग्निनाशे कृतभुजि प्रवेशे हेतुरिति मत्तःसंचलितमेव मे सुहृदः ३६

दुःपातात्हृदयं। प्रकाशं। तद्विनाशे हेतुः प्रियसुहृत्तत्त्वात् तया श्रोतव्यमरितं स्तपसुचरितं विस्तरेण श्रोतुमिच्छामि। पुरु॰। अदो अवरं णास
कुणेमि मंदभाओ मरणस्स विग्धमुप्पादेदुं। रा॰। अवरणीयं कथ्यं कथय भद्र मुखरवा। पुरु॰। का गदी। एसो णिवेदेमि। सो मेदु
अजो। रा॰। भद्र अवधानो स्मि। पुरु॰। अज्ज अत्थि एत्थ णअरे पुप्फचत्तरणिवासी मणिआरसेट्ठी चंदणदासो णाम। रा॰।
सविषादमात्मगतं। एतन्नदप्य तमस्स द्वाकरीस्स दारं दैवेन संदयस्थिरी भव किमपि तेकष्टतरम्। प्रकाशं। पुष्प
चत्वरनिवासी भद्र स्वपतेर्मित्रवत्सलः स साधुः किं तस्य। पुरु॰। सो अत्तस्सा जिह्णुदासस्स पिअवअस्सो मोदि। रा॰। आत्मगतं। सोऽयम हु ५
भ्यशनिः शोकवज्रपातो हृदयस्य। पुरु॰। तदो जिह्णुदासेण वअस्ससिणेहसरिसं अज्ज विण्णविदो चंदउत्तो। रा॰। कथ्यतां किमिति। पुरु॰।
देव अत्थि मे गेहे कुडुंबभरणपज्जत्तो अत्थसंभारो, एदिणा विणिमएण मुंचदु मे पिअवअस्सो चंदणदासोत्ति। रा॰। साधु भोः जिष्णुदास सा
धु। अहो दर्शितो मित्रस्नेहः। कुतः। पितॄन् पुत्राः पुत्रान् परवदभिसंधाय पितरो यदर्थे सौहार्दं सुहृदि च समुज्झंति सुहृदः। प्रियं तं सं
त्यक्तुं व्यसनिनि वपस्येव वणिजः कृतार्थः पंसोर्थस्य भवसरस्तिव ह्युदमीजः ॥१७॥ प्रकाशं। भद्र ततस्तथा भिहितेन किं प्र
तिपन्नं मौर्येण। पुरु॰। अज्ज तदो तेण हं भणिदे चंदउत्तेण पडिभणिदो सेट्ठी जिह्णुदासो णमए अत्थस्स कारणे ण सेट्ठि चंदण
दासो संजमिदो किं तु पच्छाइदो अमच्चरक्खसस्स घरअणो बहुसो जाचिअंतेण ण विमुक्को समप्पिदो ताअ दि तं सम अप्पिदि

तो

दो ऋद्धिसेमो केतोअस्स सपरामहरोसेदंडो अस्स कोपंपडिवण्णदुत्तिभरिओ अवक्कोत्ति अज्ज आराओ चंदरायदासो नरो जावदास
३७ स्ससच्चंदरायसस्स अस्तुरिद वरासुरो मितावजलरांपविसामित्ति सेठिजिराजुदासो राअरादेरि छं तो अहं दिजावजिराजु
दासस्स अस्तु रिद्द बंरासु रा मिताव डंबे घिअअ अत्तारा अंवा वोदे [illegible] मित्ति इमं जिस्सु ज्जा रामा अदे। राजा। भद्र नखलु व्यापादि
तम्मुं दनदास ॥ पुरु। अज्ज रादाव वावाही अदिसे खुसं पदंसुरो ॥ ४ ॥ अमच्चरक्खसस्स घरजणं जावी अदिणा खुसो मित्त वद्ध
ला लदाए समये दिनाए दिराकालरो [illegible] हो दि मेमलरास कालदलरां। राजा। सहर्षमात्मगतं साधु वयस्य साधु चंदनदास
[illegible] नास्दि सीमकाले [illegible] सा। शिवेरिव समुद्भूतं श्ररणागतरक्षया। निपीयं तेत्वया साधो यशोपि सुलदादिना ॥ १९ ॥ प्रकाशं भद्र
गच्छ श्रेष्ठी दांनी शीघ्रं जिष्णुदासं ज्वलनप्रवेशान्निवारय अहमपि चंदनदासं मरणान्मोचयामि। पुरु। अधउ राकेराउ वाएता
अज्ज को चंदणदासं मरणादो मोचेदि। राजा। स्वयमाह। दृष्यानच्च ने कव्यवसायस्तु हृदानिस्त्रिंशेन च ब्यु। निस्त्रिंशो चंदिगतजलद सो
मु मसंका शमनृत्तिं [illegible] द्व अड्डाउ लकितड्वष्णासस्ख्यः करेणा सत्वो कर्पात्मम रनिक षेदृष्टसार ःपरे मां मित्र स्नेहे दिवपामय्यपा
सा हसेमानि पुंको ॥ १ ॥ पुरु। अज्ज एवं से [illegible] चंदणदास जीविदम्मुववत्तिपिसुरीदा विएदे दिसम दसा विहागरिणडिदाणा सकु
रामि अरिद्धि दयदं मरिदुं सुगहीदणामधेअस्स अमच्चरक्खसस्स पादातुले चित्ताकरेथ मे पसादं संदेहरिणा [illegible] एरा। राजा। भद्र सो राम. ३७

हिर छप

धर

मतु मृत मर्त्तवं पावविनाशः सुहृद्विपत्तिहेतुरकार्योदुर्गृहीतनाम धेयो यः आर्यो राक्षसः। पुरु। सहर्षं पर्व इदपोनिपत्य दीश्माराः
२ निष हेदिट्ठि अदिट्ठो। राजा। उत्तिष्ठ भद्र तमिदानीं कालहरणेन। निवेदय तो जिष्णुदासायएव राक्षसगृहीतं चंदनदासं मरणान्मोचय
तीति निस्त्रिंशो पमितिपरंन्ना कष्टखड्गः परिक्रामति। पुरु। पादयो निपत्य पसीदडुर अमच्चो अमच्च पादा ऋद्धि दादए
पठमे चंदउत्तहदए गेरा अज्जस अउदासो आभात्ता सो अवऊ डाणादो केणाविअवहादिअदे संतरं अपगाहिदो तदो चंद
उत्तहदए गेरा कीसपमादो कि दोत्ति अज्जस्स अउदासवहस्सुज्जलिदो रोसग्गी घादअवहेरा विज्जा विओ तदो पकुदि घादरा
ओ जं कं पिग हीद सत्थं अपुव्वं पुरिसं पिच्छदो अणादो वा [illegible] पे क्खंति त दो अत्तणो जीविदं परिरक्खंतात्र अप्पम त्तारद्धवऊढा
णोवज्जं कं वा वोदेंति एव्वं च गहीद सत्थे हिं अमच्च पादे हिं गच्छंते हिं से ट्ठिचंद णदासस्स वहो तुरादि दोहोदि। राजा। आत्मगतं अ
हो दुर्बोध श्चाणक्य वटो नीति मार्गः। कुतः। यदि चशक दो नीतः शत्रोर्मिते न मम मांति कं किमिति निदृतं सैन्येन कोधाद्धधाविकृतो
जन ः। अपयस कृतकं तादक्षे शंकनं स विभावये दितिम मम तिस्त कारुखा न पश्यति निस्पृयाश ः। विचित्य नाग पं निस्त्रिंशकालः
धा कथमपि हि स्ते घ्रा नकामांविघाते नीतिः कालांतरेरा अकटय तिफलं किं तया कार्य मंत्रात्र। ओदासीन्येनपु तं। प्रियसुहृ
दिगते मत्कृतामेवषा रांच्या पवित्रं त्रातलमस्पस्वतचुमरुमिमां निष्क्रयं कल्पयामि ॥ २१ ॥ इतिनिष्क्रान्ताः सर्वे षष्ठोंकः ॥ ततः प्रवि
धा

रू

३८ शतिचंडालः॥२॥ श्रो मलधश्रज्जा श्रोसल य श्रदेहमाणावाश्रवे दा श्रदिश्र। जइ महहलक्खिदुंसेपाणेपि हवे कुले कलत्ते श्रप
लिहलधत्ता विसमिवला श्राव त्थं सुहूलिणा॥३॥ श्रविश्राभोदि पुरिसस्स वाही मरणं वासे विदे श्र वत्थ मि॥ ला श्राव त्थे डणा
से विदम्मि सश्रलं कुलं मलदि॥४॥ ता श्रदिस्स पत्तिज्जेह ता पेक्खह एश्रं एश्राव त्थ श्रारिणो से त्थिचंडाणं दासं वुज्झ ढारं णी श्रमा
णं सपुत्त कलत्तं। श्रुत्वा श्राकाशे श्र ज्ञा किं भणह श्रत्थि से कोवि मो केदा पा श्रात्ति। श्रज्ञा श्रत्थि जूइश्र मच्चलवदस स्साय
लि जणस्स मज्झे दिण्णं। किं भणाधु· एसो सलणाग दवखलाश्र त्तणो जीविदमेत्तस्स कालेणोइ रिसंणा फ ज्ज कलिस्सदित्ति।
श्रज्ञाते णाहि श्रवधा लेहसे सुहंगदिं एत्त केदाणि। तुस्सारं णत्थ पडिश्रारो। ततं प्रविशति द्वितीय चंडालानुगतो वध्यवेष
धारी मलस्कंधेनादाय कुटुंबिन्या पुत्रेणचानुगम्यमानश्चंदनदासः॥ सबाष्पं। श्रह्मारिसा णा विजहिं णिच्चं चारित्तभंग भी
रूणं। चोरजणोविदमरणं हो इत्ति णामोकश्रंतस्स॥३॥ श्रहवा णाणिसंसाणं उदासीणो सुइश्ररेसु वा विसेसो श्रत्थि। तथा
रा हि। मोत्तूण श्रामिसाइं मरणभएण तिणेहि जीश्रं ति। वाहाणाम्मु द्धहरिणाहं तुं को णाम णिच्छंधो॥४॥ समंततो [illegible] वलोक्य। भो ६३
वं रेपि श्रवश्रस्स जिसड्डणस्स कहं पडिवश्रणं पि णामे पडिवज्जसि। श्रहवा दुल्लहा ते वुमारेणउस्सा जे श्रस्सिं काले दिट्ठि वं हेति
हुं दि। सबाष्पं· एदे श्रह्म पियवश्रस्सा श्रंसुपादमेत्तकेण कश्रपदीकारा सरीरेहिं णि श्रत्तमाणा पित्थे हिंदीणवश्रणा राम· ३८

वाहगरु श्राश्रदिहीरमं श्रणुगच्छंदि। परिक्रम्य चंडालः। श्रज्ज चंदणदास श्रा श्रदोसि वज्झट्ठाणं णा विसज्जेहि परिश्रणं। चंदः। श्रज्जे
कुटुंबिणि णिवत्त सुवज्झट्ठाणे श्र म्हे संपत्ता णा अत्तं अदो श्रवरं श्रममिं श्रणुगच्छिदुं। कुटुंबिनी सबाष्पं· परलोश्रं पच्छिदो श्रज्जो
णादेसंतरं त्ता दाणिं श्रश्रालो कुलश्रणस्स णिवत्तिदुं। चंदः श्रह किं ववसिदं कुटुंबिणीए। कुटुं· भत्तुणो चलणो सुश्रणुगच्छं
तीए श्रप्पा सुग्गहो होदुत्ति। चंदः श्रज्जे· दुव्ववसिदं तए दाणिं श्रज्जाएए सपुत्तश्रो श्रमुणिश्रलोश्रसंववहारो श्रणुग्गेण्हिदव्वो॥
कुटुं। श्रणुगेण्हंतु णं पसण्णा श्रो कुलदेवदाश्रो· जाद पुत्त श्रपच्छिमं पिदुणो पाएसं। पुत्रः। पादयोर्निपत्य· तात कणिं
ताद विरहेणा किं श्रणुचिट्ठिदव्वं चंद। पुत्त चाणक्कविरहिदे देसे वसिदव्वं· चंडा। श्रज्ज चंदणदास णिखादे सूले ता सज्जो दा
णिं होहि। कुटुं। श्रज्जा परित्ताश्रध २ चंदः। श्रइ जी श्रवक्खले किं एत्थ श्रक्कंदसि सग्गगदा वखु ते देवा णंदा उड्डुरिवुवदं परिश्र ख
णं श्रणुकंपंदि। श्रसंश्र। मित्रकज्जे विणासो णा पुरिस दोसेण ता किं णादं हरिसहाणे विरोइश्रदि। प्रथम चंडालः। श्ररे विल्ल
वत्त श्रागेण्ह दं दणदासं स्वश्रं जे वप लिश्रणो णमिस्सदि। द्वितीयः। श्ररे वज्जलोमश्राएस गे एहामि। चंद। भद्दमुहुत्तं पडिवालेहि
जाव पुत्तं परिसजामि पुत्रं मूर्ध्नि समाघ्राय· जाद पुत्त श्रश्र वस्सं भविदव्वे विणासे मित्तकज्जं समुव्वहमाणो विणासं श्रणु
हवेहि त्ति। पुत्रः। ताद किं एदं पि भणिदव्वं कुलधम्मो रक्खु एसो श्रह्माणां मित्तिपादयोः पतति। चंडा। गिण्हरे श कुटुं। श्रज्जा परि

दनदासस्वार्थप्रधानो यंजीवलोकः हलतमुपालंलेनेन जम्बुरवनिवेध तांतावदुरात्मनेचाणक्यायाचं ५

३९ त्रिवाच्छधश्।ततः प्रविश्यपटाक्षेपेण राक्षसः।भवतिन भेतव्यं।भोभोः स्वनापते नरदलुव्यापादनी यमेतं दनदासः।कृतः।येन स्वामिकु
लं रिपोरिवकुलं दृष्टंविनपश्यतु रामि त्रारणोव्यसने महोत्सववइवस्वेच्छमेयेनस्थितं।आत्माय स्यदर्धायनः परिभवक्षेत्री कृतो श्री २
पिप्रियस्तस्येयं मममन्दतुलोकपदवी वध्यस्तगावध्यतां।५।चंदः।विलोक्य।सखाष्य अमच्चकिंएदं।राक्षः।त्वदीयस्य सुचरितेक
४ श्री देशस्यानुकरणं।किलावंदाः।अमच्च सहं पिमे शिप्फलं इमं आसिकुणं तेण राणा महप्पिअं अणाउ चिट्ठिदं अमच्चेण।राक्षः।सखे चं
डालधाकिंतिं।सन्धाः।दुः कालेपिकलावसज्ञानचलि आरोः परैरकृतानीतं येन यदास्विनासुलघुतां मोशीनरीयं पयशः।वङ्काना
मापिवेष्टितं सुचरितैः क्लिष्टं विशुद्धात्मना पूजार्होपिसयत्कृतेनवगतः शत्रुत्वमेषोऽसिसः।६।प्रथमचं।अलेवि जनतेआ
तुमंदावचंदणदासं वोरिहव्वार अस्स आरम्भकतं अचिट्ठ जाव अहं घाणक्का आणिवेदेमि।गहिदे अमच्चरक्खसोत्ति।द्वि
ती।व्यवज्झलोमञ्चाए वंमेदु सपुत्रदारेण चंदनदासेन सहनिष्क्रांतः।प्रथमचंडालः राक्षसेन सहपरिक्रम्यएत्थ कोणिवेदेद
दावणं एदउलसिलसं वअम्बूलणाकुलिसाहमोलिअकुलसाहिपडिडावकाहपडलधम्मसंठावआहअञ्जचाणक्काहाराहः।
स्वगतं एतदपि नामममोत्तव्यं।चंडालः।एसोखुअज्जरामी इलदासं उमिदबुद्धिपुरिसआलेगवि [illegible] अमच्चलक्खसेत्ति।ततः
प्रविशति जवनिकावृतशरीरोमुखमात्रदृश्यमानः आक्यः श्मश्रुकपयशकेनोतुं अपिस्वाकला [illegible] पिलोवद्धः पटांतेशिरदीया। राम. ३९

श्री ३

पोः केनसदागतेरलिगतासघः समापादिता।केनानेकपदानवासितसदः सिंहोर्पितः पंजरेभीमः केनचनैकचक्रमकरोदोर्भ्या
प्रतीर्णोर्णवः।७।चंडालः।रणी दिवुद्धिणा अज्ज जेण।चाणः।भद्र मा मैवं।नंदकुलद्वेषिणा दैवेनेति ब्रूहि।राक्षः।विलोक्यात्मगतं।
अयेअयं सदुरात्मा अथवा अयं समहात्मा कौटिल्यः।आकरः सर्वशास्त्राणां रत्नानामिव सागरः।गुणैर्नपरितुष्यामो यस्य म
त्सरिणोवयं।८।चाणः।विलोक्य सहर्षमात्मगतं।अयेअयममात्यराक्षसः।येनमहात्मना गुरुभिः कल्पनाक्लेशदीर्घजाग
रहेतुभिः चिरमायासिता सेनावृषलस्यमतिर्मम।९।उ जवनिकामवनीयोपसृत्य प्रकटं।भोअमात्यराक्षस विष्णुगुप्तो भिवादयते
राक्षः स्वगतं अमात्य इतिलज्जाकरमिदानी मिदंविशेषणं।प्रकाशं।विष्णुगुप्तमामांस्प्राक्षः श्वपाकस्पर्शदूषितः।चाणः।भो
अमात्यराक्षसनायंश्वपाकः अयंखलु दृष्टएवभवतासिद्धार्थको नामराजपुरुषः योप्यसौ द्वितीयः सोपिसमिद्धार्थकनामा मि
राजपुरुषोपएकः सकटदासो पितपस्वी तं तादृशमजानन्नेवमया कपटलेखं लेखितइति।राक्षः।सहर्षंस्वगतं।दिष्ट्याशकट
दासंप्रत्यपनीतो मेविकल्पः।चाणः।किंवहुना।एषसंक्षेपः।भृत्याभद्रभटादयः सचतथालेखः ससिद्धार्थकस्तच्चालंकरणत्रयं
म सज्जेवतो मित्रंभदंतोंकिल।जीर्णोद्यानगतः सचापिपुरुषः क्लेशः सचश्रेष्ठिनः सर्वोसौ।इत्यद्धेकिंलज्जांनाटयन्नृपलस्यवीरभ
वता संयोगमिच्छाम्यहं।१०।तदयं वृषलस्त्वांद्रष्टुमिच्छतिपश्यैनं।राक्षः।आत्मगतं।कागतिरेषपश्यामि।ततः प्रविशतिराजा

र्मे रा

४० विभवतस्थपरिवारः। राजा। आत्मा। विनेव युद्धाद्दोर्येणापराजितं दुर्जयं परबलमिति यत्सत्यं लज्जित एवास्मि। ममहि फलयोग
मवाप्य सामंतानां नियोगेन विलङ्घितं गतानां। नमु देवमनर्थकबोधामुरवानां निजमन्त्रणी शयनस्य ततस्य निष्ठा॥१३॥ अथवा वि
मुर्णीकृतकार्त्स्नकोपि जेतुं भुवि जेतव्यमस्तोस मर्थ एव। स्वपतोपि ममास्य यस्यतं त्रेगुरवो नाध्यति कार्यं जागरूकाः॥१४॥ चारणः जय
मुपसृत्य आर्य देवं चन्द्रगुप्तः प्रणमति। चारणः। वृषलसंप्रवासे मम सर्वाशीषस्तद्भिवादयस्वात्र भवंतममात्यराक्षसं। अयं चैष
त्कोमात्यमुख्यैः। राक्षसः। आत्मगतं। योजितोनेन संबंधः। चंद्रः। राक्षसमुपसृत्य आर्य चंद्रगुप्तः प्रणमति। राक्षसः। विलोक्य। आत्मगतं।
अयमपंचंद्रगुप्तः य एषः। बाल एव हि लोकेन संभावितमहोदयः। क्रमेणारूढवान्राज्यं यूथैश्वर्यमिव द्विपः॥१५॥ प्रकाशं। राजन्
विजयस्व। राजा। आर्य जगतः किं न विजितं मये निश्चिंतं त्वयि। गुरौ षाड्गुण्यचिंतायामार्ये चार्ये च जाग्रति। राक्षसः। आत्मगतं। स्पृशति
मां भृत्यभावेन कौटिल्यशिष्यः। अथवा विनय एव चंद्रगुप्तस्य मत्सरस्तु मे विपरीतं कल्पयति। सर्वथा स्थाने यशस्वी चाणक्यः।
कुतः। द्रव्यं जिगीषुमधिगम्य जडात्मनोपि नेतुर्यशस्विनि पदे नियतं प्रतिष्ठा। अद्रव्यमेत्य तु विविक्तनयोपि मंत्री शीर्णाश्रयः
पतति कूलजवृक्षवृत्त्या॥१७॥ चाणक्यः। अमात्य इष्यते चंदनदासस्य जीवितं त्यतः संदेहः। तद्यदि सत्यमेव चंदनदासस्य जीवितमि राम.
ष्यते ततो गृह्यतामिदं शस्त्रं। राक्षसः। भो विष्णुगुप्त मा मैवं। अयोग्या वयमस्य विशेषतस्त्वया गृहीतस्य ग्रहणे। चाणक्यः। अमात्यराक्षस ४०

राक्षसः। भो विष्णुगुप्त कुतः संदेहः। चाणक्यः। भो अमात्यराक्षस अगृहीतशस्त्रेण भवता नानुगृह्यते वृषलः२

...वैकाः प्रोमेरयुग्मासे नेः स्नानाहारविहारस्थान शयनस्वेद्दास्तुरेव
...वंदः पश्येयेतः नपरिकस्यनाव्यतिकर प्रेक्ष्यसंयमाद्गजानां॥१८॥
...रासस्य जीवितमस्ति। राक्षसः। भो विष्णुगुप्त नमः सर्वकार्यप्रतिप
...ब्रल अमात्यराक्षसेनेदानीं गृहीताधिकारेण अनुगृहीतोस्मि
...वतो। पुरः प्रविश्य। जयत्वार्यः। एषोरवलु भद्रभटप्रमुखेर्हिस्त
...रश्रेस्तु शिरायत्त सोपमाराणां। चाणक्यः। भद्र निवेदयता ममात्यराक्षसा
...कृत्यमामिदानीं विज्ञापनायां सुरवरी करोति कौटिल्यः कागतिः प्र
...यकेतोः किंचित्कालोंतरमुषितादिनिःसारितः तामस्य प्राणाः। राजा। वा
...मपितं वोमात्यराक्षसस्य प्रथममनुरागपुरुषमवलोक्य। भद्र मद्वचना

म सम्यः कुसममकोक्राविज्ञाविजोदेवप्यंद्रगुप्तः प्रयच्छतिमलयकेत
प्रायेचास्मिन् उत्तरा गंतव्यमितिप्रुत्। ॐ अ ज्ञो आ राज्ञा वेदितं । चाणा । त्तिष्ठ
न स्तुप्री तम्प्यंद्रगुप्तः सम्राज्ञापयति । य एष अच्छी चंदनदासः स इष्टथिव्यां
यतोसर्वं वंधु नमोऽस्तु इति । अथ वा अमात्यराक्षसेनेन रिकिं दत्तिभ्यः
प्राणप्रतितेन मया केवलं वध्यनौश्शिरवा । १७ । कुरु । जं अ ज्ञो आरा
ः प्रियमुपकरोमि । राक्षः । अतः परमपि प्रियमस्ति । यद्यपरितोषि
स्थितस्याचुरुपायस्यभागं तकोटिं मलयपरिगताभिप्रियेभ्यः तथा
पत्री मृत्युपर्यन्त्यभिरमवत्तुमहीपार्थिवो धर्मवर्ती ॥ २८ ॥ ॥ राम.
हुं
८२